

गुनाढ्यायबृहत्कथा

हीतोपदेसतीनी

ॐ नमः सर्वज्ञाय ॥ सिद्धिसाध्यधिकामस्तु [illegible] ॥ [illegible] यु

[illegible] गणवन्दिता ॥ [illegible] ॥ [illegible]

[illegible] ॥ श्रीमद्वज्रधारेण [illegible] १

[illegible]

[illegible] सिद्धि [illegible] ॥ १ ॥ [illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible] ॥ २ ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ ३ ॥ [illegible]

बथ्यायेन बस्यक्तु ॥ समुद्र मित्र हृदस्सं मुयंसाङ्क मजर्स्यवं ॥ ० ॥ विद्याशास्त्र ग्रन्थशास्त्र स्वहविद्य

प्रतियकत्य ॥ श्राद्याहाय्याय स्वहृद्ध विविपाथीयर्ववाद ॥ ॥ यत्नवकाजनन ग्रन्थक्लावानाय

थ्याकवक्तु ॥ कथंयुलन वालानां निमित्त हिहकथ्यक ॥ ० ॥ गथ्यम उद्दाक गुनिथ्याय जनयाड २

थ्यवमव न गुथं साङ्क ममवक्त मनुष्य निथ्याय जनक वथ्यकन मर्वक्त वालवानिमित्त मयकानिमि:

हिन नाना कथ्यायां याकयाड निमित्त जनक्षाय ॥ ५ ॥ मिकनाक समहृत्ड्स्वथ विगहस्मयिथ्व वव ॥

यक्व वज्राक थ्यायस्या त्वाथ्यसङ्ग यत्तलिथ्यम ॥ ६ ॥ मित्रनाक महकुद वियाक मान्थि थ्वआदिनवं

धनजनना नानीति वासंमयाक्षाय थ्ववं ॥ ७ ॥ श्रुतिवामीवथ्वीवीव याकलि पुत्र नाम थ्यस्यक्त

गवं ॥ ॥ यस्थिनं वनसगजमीनस याकलि पुत्र नाम नगवयु गुविदव ॥ ८ ॥ नक्रवसह्वेस्या:

मीगुलाय्यव हस्र दक्ष्मना नामनवयाकि वासीतु ॥ ० ॥ थ्वनवाव स समम कुलाक याय्या मिसमकजु

मनमथ्यन सुदर्शन नामवाजायं राक्ष्यादविक्षावं ॥ ९ ॥ सवकह्याविमवकाक्षनायि यथ्वमा

श्री

नं श्रावकयं संघायव॥ ॥ अथ वसोस्यं नकं बविज्ञाकदास्यं सछिनं नगववासिन यदया श्रावक नि:

यूनास्यं विज्ञाव॥ १० ॥ अनुयव संघयास्य दियवाज्ञाथय दगेदश मस्वेस्यलाव नंगमन्नं यसना:

स्यध्वनायवगश॥ ० ॥ अगाश्व श्वसमा अनन्ननाना संघयमी ववाव मवनया दाश्य कन्त्रादिन नानाव

मज्ञाना यँ श्वनक्रवनीकिश्वव लवदश्ययाव वर्थिं शगमन्त्रधायायवसमकनावाश्वमिस्याश्वगमन्त्र मसव:

स्कं वानवकुस्यध्वकं॥ ११ ॥ यीवनं धनसम्यक्ति४ यकुव नाविववकाना तश्चकेव श्वनथयकिमुय:

१ मननर

२

ग्रवकुयुयं॥ ० ॥ थोवन धनसंयद यकुन श्वय ञ्चनाविवकामन्नु गमन्त्रमसव श्वानिश्च नश्चुदंथ:

थश्वकां॥ १२ ॥ सुस्याव श्वीमन४ यूदाश्चमन धियकगमन्त्रा॥ नामनुश्चवना श्वियमना४ मवाकों

विन्त्यामाव॥ ० ॥ श्वयवा वमयुषिनं मनुश्वनयठयाश्चाकनायाव थवयुवयनि गमन्त्र मसव:

नावयं वाजास्यं वकमयावकां विकवयनं॥ १३ ॥ वाकोद्नथयूक्तजाकन श्वनविद्वान्नश्चाम्भि वश्वना

मनवज्ञयाकिश्माव ज्ञ४थीठयवयेस्त्नां॥ ० ॥ ववाजास्यं गश्चक्किवयव श्वावसानायजायवयाव

स्तूपार्थी याति नमस्कृत्वा धर्मिकामन्त्रवत्स्वां युक्ता श्वेतसम्या भीताकृतया तुष्टकर यावत्सु:
य भिक्षाबोधयुस्वं कृत्वार्थं स्तुत्वां बुद्धत्वमर्वं ॥ १४ ॥ विंश ॥ सत्वानां मनोजन्म नजाति विसंसमनरविं ४
यावद्यहिं निसंसारे स्तुतः श्रीमान् जायते ॥ ● थयछनवंज्ञायवय वद्धवज्ञानन्दवधाय:
मत्व थयवं ग थं ह्रुदविद्याममसयवं मनुष्यमाबनश्च्रं स्मिसवूयवाज्र यविवद्वेसंसावसमसमः
स्कसंसार सर्वंज्ञायव यथाय विद्यावन्क्ष ॥ १२ ॥ ब्रुयथवा युक्तिमामनमननावंक यविकेनवाचि:

* बुंगाजन २

नवयथवनर्वं स्तनगुणविद्यार्थयाथवं स्तनगुणयथववसथवं थवद्यानाग्रहे सवानस्यं निस्यं दक्षसावि:
ध्यानास्यं शः स्मियादन्कयाथवं ॥ ॥ विं ३ ॥ ब्रुवगथं काविनाकाविकवद्धि मद्धकाया यिनक्षवः
नीवकगुस्यमद्धाद्धिभयनंकवः ॥ ॥ गाथ्याववसा ब्रुवस्यं ज्ञुयगु वियद्वथैर्वनद्ध वा ग्रुहाकः
युवयथाज्ञवसानं मन्त्रयद्धमवामश्रदवजैवावयाथं ग्रुवथयियया नवनयादयावकि दिगंवतः
ज्ञयमाव नावायनं समद्यववामासाद सथ्यायथमाव ॥ ॥ ब्रुयिवायदसाविनवक्षाविश्र

यिं घ यमस्वं २ १

४३२१

गन्धर्व्वआत्मानयाद्रावम्रीयाद्राकहुंवनार्मं॥ ॥तथाराङ्कीं॥मामकीवीयिनाम्रनुयत्ताम्बायय:
नयाचिनशानग्राकंन्दसतामश्वहुंसमश्ववत्रायथा॥ ॥मामवेवियाहुंवयूम्रनुयाहुंश्वयनि
यांद्राहांमहस्यांवातवामगास्त्रग्नसमयायिडाद्वाधम्मकुंसनावसवाश्वावश्चंसताम्रश्च: १
त्यवर्तं॥ ॥नूयश्वेवनमस्यन्नाविग्नातव्रातमेकंवा॥विद्याहुंमानव्मानकनिगेश्वाङ्ंवांधु
का॥ ॥नूयवम्रयाहश्वेवननमस्यन्नयाहक्रिडव्रातमजायवयाह्रिंथवव्विद्यामसवकाव:

वसाहिनक्रवयवावसाधीनंत्रयूदथूजिमवयावसामसवविक्षय॥यस्त्रिमवयावसायस्तुवंह
यू॥ ॥श्रुत्रात्रवविस्लूसमानामसमहायस्त्रिमश्वासवातलीगिगास्त्रवत्वकाहुहस्यावविवा:
ववीम्॥ ॥गन्धर्वराजास्यंत्राह्लादयवाहम्रावविस्लूसमानंथायामहायस्त्रिमसकवनीवि:
गास्त्रसवहुहस्यावितृवेवनसमसामकवदसवथायंश्राह्लादयवर्मं॥ ॥दवव्रातमेक
वातवसाकयूत्रानीविगाहयिदुंगश्वम॥ ॥राजाराजामहूवयावयाथिंश्वनिम्रीतवूव:

सजायव थाम्ह थाक यूत्र यानि नीति मयुम्ह मयकजि वम्ह थवं॥ ॥ यकठ॥ नाम्ह यानि हिमा
वाविकुजी थारु लवनी रुवनु॥ न थायाव गवनायि गुवा वथकवव॥ ॥ थवनने नयु
जी गथाहनाना थवकालन मयक्क मदाथवजी थायह्ला मदयवं जुगं मदयवंयुनवगद्मियवा: ९
वघमनमवं हगुन यज्ञायाथ्वं वाहावमयज्ञायमह्व॥ ॥ अयम्ह॥ जम्मिनुदिनिम्मन
मात्रुस्वयवमयिजायव॥ आवाथयम्ह वानाजम्मावायमनह्मतठ॥ ० ॥ स्तूवयावयाथि

यु निम्मिलहाल वाजुवंगमजायवया स्तूवयावया यूत्रयानि आमाथ्वभवसायह्म वायुनिया:
थानि मम्हालजायवयंसंरुयमहुथ्वं स्तूवयावयायूत्रयानि आमाथ्वं नीवन्ह्यमक्वावथवं॥
॥ अयुनठय म्भासायक्क वनमवयूवाम्नी निजि यामहयिठुं सम्मीम्मि॥ ॥ धूविनयूवानह्ना
स्तूवयावयायूत्रयानि नीति मयवाहयूवम्हथवं॥ ॥ वाजामविनयंयूवठा मवंयूनवूव
व॥ ॥ वाजाम्यविमकल यंहवाथ्यविझादाव विम्हसमाखंयिनायव॥ ॥ विंनयि

सूमनःस्यङ्क द्यावाद् क्विसम्बांगिवश्यां ग्युम्मा क्षियायिदवल्वं मन्हृक्ष्निःसयायिमिस्ह्वितश्वां ग्युगयस्याय:
थ्याद्यगिवोहृयुं बविसं ज्यानदीयश्वं ॥ नथ्यासल्तिक्विवस्वेनदीनवध्वायिद्विश्वत ॥ ० ॥
गथ्युडद्यगिविसवाद् नानावस्तुसमस्तं सय्युयाकजुनसमस्तं वजवक्कजुव थ्याकाथंसय्युवु: १०
यव सयंगनत्यानद्याव दीनजाविन्हवसांवं कजवक्कसयु ॥ वाकेदकः यासम्सयुवाधायावव:
यद्गुवुनत कवक्ष्ःयुमामाविलुह्या नस्यविन्हसमेलःसाब्दमानयुवःसांवं वाजयुवासमयुपावास:

स्य
श्वा ॥ वथ्वविनयुवयावंन्हजयुवयुनि विश्यामस्यवमानथ्वं ॥ निंभिशास्तुस्यवायथ्वं ख्वयवा ॥
वहयाजास्यं विन्हसमीवां नानामाथथाद नानावस्तुवाविधावबाजयुवयनि बदक्कावं ॥ ॥
कृथयासाद्युस्तु सल्वावविस्तुनांवाजयुवाणाम्या युस्मवजामनारावस्तिवाद्धवीव ॥ ० ॥
थवनिथ्युंडेमयुन्हयवसविक्काद्धावमस्यासनयाद्यावाधावधयस्युवसविन्हसमास्यवाजयुव:
यनिसाह्ववन युस्थाविवायं आक्रन्दयमवलं ॥ वाकायगास्तुविनाद्नकावासायुक्विधीमवां
हे२

थ्वगननतुमर्थ्याम्हं निर्तयावलाहनवा॥ • ॥ज्याथ्रआदिननानाग्रास्तसमनसथ्रुप्ल्याससयाडन
ह्लानिमहायानवालहनिव। मूर्खक्मनथ्वसनमसवनस थ्यंवावहनिवह्मनसं मिसावावह्लावावि
धावथ्वश्रआदिनवावहनिय॥ ॥वजुववांविनावायविविवित्रांवावाव्रुम्भीदीनांवथांवथ्या ११
मि॥ ॥विष्णुसमांस्यं वाजयूत्रयनिह्लोओविव।थ्वमिनष्णुसवावसनववमसंस्यं वयन:
हनमाश्रुविश्रुयूविह्य श्रायवायवयाज्रनह्मायधवां॥ ॥वाजयूवेवूकं॥ह्मथ्वाश्रु

धुमथ॥ ॥वाजयूत्रयनिस्यंश्राह्लादयवनह्लाक्रनडनवधवं॥ ॥संयमिमिमनाक
७ क्ष्महयवयेयायमाय्घ्लाक४॥ • ॥विष्णुसमास्यं श्राह्लादयवावंथ॥मिवलावयं ह्लायडक्नमि:
वलावया आदिग्लावधयुदि॥ ॥श्रुमाधनाविलदिना वृद्धिवक्ठवहलमा॥माधयश्या:
मवाथ्यानिवावक्राम्सषुमाय्वव॥ • ॥धनमायावधामहाद्भथियाडवाय श्रवल्मदिनबह्लिव
क्मसहत्ववावावडलमवाश्रीमाधवयंवायवायवाय्रववास्रु थयक्मस्यंधवं॥ ॥वाजयूव:

हुरा कथमक्तु ॥ ० ॥ नाऽकृतं नत्वा मायया वध्वबन्धाव ॥ ॥ विक्रममीवाव ॥ ० ॥

विक्रममार्गस्य हादस्यवनं ॥ ॥ कुञ्जिमावव नीनीव विशालक्षया नालीकवृक्षा ॥ ० ॥ कृत्ता

ह्विमें ध्रुवाव नीयाविवस ज्ञादाकमा न्याविमिमन्नु मादव ॥ ॥ तन्नानाविधमादामवावा:

नीयत्रि धानिवमक्ति ॥ ० ॥ ध्यासमासनानादिमदश्वाक्रव ध्ववयाश्वयनि याविमवववर्धान ॥

॥ अधवकदाविदवमन्नायां वञ्चायांवमाव नत्नुगवनावानिजगवनि ग्रामदिनीनायष्ठावञ्

ॱ यहनर

मसि नवृयमनवा नामवायमरयकञ्चञ्चना कुमिवद्विनीयं यामकसं श्राधमयश्वत ॥ ० ॥

धनविश्वेसूक्तयायुस्तावमवलक्ष्मि गवञ्चकमृदिनीनायवा यञ्चञ्च ॥ किनया इवीयात्रं नायुवसा

याडविश्वालनवृयमनवा नामश्रावनवाक्रिया सप्तहलाकं मासांधावं द्वितीय यैमदकवउर्थिया

गञ्चहावरदमवरसनं ॥ ॥ आयया गवना धिदेदगनं नञ्चानवि ममिदं हगीयमानि हस्या:

ज्ञायदनसवञ्चञ्चमनश्चात्रालयज्ञिव ॥ ० ॥ यथश्रुविसमक्तिउयवधाव नवृयमनवा

विकलमद्याग्रवदयाय विकवयर्वं थनिब्र कावकालसक्कमकिंठमायमालिवद्धमधवं गावयालथ
मवलबदार्थं ध्वयालिवविव वविवमावयाद्धवनं॥ ॥शावयनमद्धयागिवयद्यनशवा
निव॥ दिवस्थदिवद्यमृद मांविङ्किनयधुमः॥ ॥नयाव॥ विमखिनामिदमवद्यंवालयं १३
॥उद्यथाद्यवाद्धवं महद्भयमृवस्थिनं॥मवनंयाक्किणयानां किमयनियाविद्यमि॥ ॥
कृगयवनयाक्षेनवभूलक्षणानवकीयेजालंविक्रान्नीं॥ ॥श्वनलिथंथमवननद्भवनद्याः

श्वक्षावावजालयाद्वनयायामस्कवं॥ ॥श्वकिम्नवावस्थव विवागिवानमवयावव॥जावमः
यविद्यावाविद्यविविमयोक्षवुवननालवलावयामाम॥ ॥थमवलनथथ्यागद्भूयंवय
ववम विवयीवलामववयूनीयायाजावववयनीनुनवयवीवाववंथथायमवयावयावद्यावव:
यायवनं॥ ॥ननकक्षगुलवनालख्याक्रयामात्यद्याद्धवायाकयाज४॥ ॥थश्वाकिद्व
वनयाम्नवववयूनिमवाजयदावयाजावबद्यनिनववयूनियनिद्यवं॥ ॥कुशानिः

ड्री लक्षणुलवनानां संकचं४॥ ० ॥थप्मिंदनिर्जगयापमसनुद्यपानाममदवपाविदपमसव
मप्ता॥ ॥तत्निवुद्यवांकावलसकडंयद्यामियायवानलवडुलवानायासनास्मारिवयिवथ
नावितद्यां॥ ० ॥थवाविनिवुयमयासदूकद्यमवनमकववहावध्वनद्यपाविसवाकवा १४
दर्दूर्जिद्वयायविध्वक्रयरुव॥ ॥कवांनद्यक्कवासनमयुपंवाम्भूकव॥द्वकयावुगमी
यायकु४यथिवंसद्भवायथा॥ ० ॥गुवाथंधवसामवद्भकंकनन्धदावथ्लायकयावकंवं:

नवलमदायुद्रयद्याथवृनमयुयेवसमावधंश्वमनुद्यमावक्काददवय॥ ॥कायावाडवु॥
कथमकत्॥ ० ॥दवयुनियनिर्धाश्रमायागथ्यधकंदनं॥ ॥मादुववीत्॥ ० ॥वाजाव:
वयूनिंवाद॥ ॥श्रुदमवाचादक्षिमावण्मुववमयर्धी॥ ० ॥जंवकाकेदक्षिमावधम:
ववयमंजीवदायंस्वयंवयमंवायदद॥ ॥तवाद्दैयाद्य४मस्मावा४ङ्काग४मधस्मव
स्मावस्कन॥ ० ॥ग्रायमुक्कनभाउद्भयावलाद्यवमक्कगवयावयुक्कविधीयाविवसवावाः

व वंनववकवकव्हावं॥ ॥कोकायान्हु ह्नुवंक्ष्णकोक्कनगुस्कवं॥ ० ॥स्त्रि ववववमनुष्य:
ध्वमवष्ठिवांवनविद्यनाधवं॥ ॥मभावा काव्रुक्ष्ण कनविद्याव्हुनावाबिवं शयानवकव:
यिमंसवविं॥ ० ॥थश्रयाव्रुनक्षायाव्हावमस्थिनंवगववयुवुयमवाभयाकनविंकवय १३
वंश्रकाश्चयाश्चानघुयाव्हमवाव्हवमनांवायवंनववस्थवं॥ ॥विंत्वमिवथमस्कव:
धृविनविश्विश॥ ० ॥थथिवध्वनवायववम वनमवयमानिमायवं॥ ॥यवश॥श्रविद्य

दि मुवाक्रमिनायविज्ञायवगुवां॥यवश्लिविपयवंमल्लो मुकवंवयिमुख्व॥ ० ॥विवाव:
विवाथीक्वनवमुक्कोमंक्कतव॥ ० ॥यश्रवनवन्वंममस्कयवावक्ष्नवायवथिनि॥
॥नथवाक्कं॥नमंगयमनाबुक्कनवाकवाक्षि वयाकि॥मंगयंयुनवाबुक्कयविज्ञीवविवयथु:
वि॥ ० ॥यथवथवमामंगयमयमजायं मनुष्यनमवदवायमवामंगयम ज्ञमजायान्य
कमांमयववानिव॥ ॥वनिवृयथामिमायश्रवागंवुव॥ ० ॥थवनवक्वनिवृयथायध्व

वं विकृ व याव ध्वुदार्दं ॥ ॥ वृधुवनकदं ॥ ॥ वं कन यन थकंठ्वा ॥ ॥ खाखादस्यं थ्या:
खोदगंयाति ॥ ॥ थ्याथुननादानथंज्ञवादवंवनवाना ॥ ॥ थ्याधुउवाय ॥ ॥ थूनथ्वर ॥
॥ हूं यानिमदंस्यावशीवाद्याज्ञा नालिवननवदकुठवाथंनविश्वसकुभि ॥ ॥ थ्यावयज्ञायत्र १८
उनाउंद्वयाव मविगीनयाद्वदानविययाउयाठाजंजामिदाय वंदावजुथ्थिंदवयथ्वविश्व
समयाव ॥ ॥ यमठ ॥ हूं याथ्थयनदानानि कायठसर्वधुनि जमा ॥ धुयाह हूं तिमाजी

यंथ्वस्थेयाधुविथिठस्तुना ॥ ॰ ॥ हूं स्थाथ्थयनुदानमयमथ्थ थिनिजमा श्लाकथ्थयामाधर्म:
यालंथ्वकंज्ञायंमय ॥ ॥ मत्रथ्वीघुठश्रेज्ञादंनाथिममिमथ्या ॥ श्यवमुमठुवेज्ञोमदा:
ममयाक्तिथ्थति ॥ ॰ ॥ ममवेमावाज्ञाकाविवक्तियनस्वकमगवंवनमयियकुभेवाभेविमठ:
मियामि ॥ ॰ ॥ थ्यकनजनलिवा ॥ किज्ञयंथ्वनादाथ्यमथ्वादकज्ञनमयियाकज्ञयाहनमवं
वियङ्क्याथ्यवं ॥ ॥ विंत्र ॥ कथ्थायमनुथ्यानुथ्याग्रनयथ्यवंज्ञावनज्ञायंमयाथ्यमलयवं:

मवा॥ ॥येन४॥यवतानुगविञानावत्थ्जुहूंवनिसूपर्द्दखिनी॥युमाक्षयमिनाथर्म्मैंयस्मावायुम
मयिम्बिर्ज्ञं॥ • ॥यूमाश्चुंश्वमस्मालावनंहूवयूनजाक्यायिगयस्याद्वंडाक्षायूक्रुनीन
हूनयूसामियाश्च॥वनकर्स्वंवाभवकायमनंवदंक्तंलावनसन्वैंप्द्दाद्दामिसायायूस्मीनवबज्ञा॥ १८
स्मस्मवयाजद्दानवबहुनायूवक्षुदयानसाड्ययायायायानसावयाँवाक्ष्मगनत्रिवलिवमायूसांक्ष:
दंकुवसार्व्वदानक्मासांहुनयायू॥ ॥मयायम्मैश्मक्मायाश्चाज्ञानिशुनूमयि॥ • ॥ज्ञनवर्म्म

×धसूत्रिंयाके ररकाचबवनसांश्चनातडावन्नमायूर

गास्कुक्षावस्यंहूदनयाहृदय॥ ॥ग्राणयमात्नना रीस्युकृ त्वानगयिहजनथ्यात्स्वालीयनानरू
यानांहूयांक्षुत्वक्रिसायव॥ • ॥थवजिवत्राल्यायश्वजयत्त्रप्रयंश्मवयायवत्रामायारुथंभव
वदयाबावझ्म साध्वज्ञनधाय॥ ॥स्वयवक्ष॥वत्यास्यानववानव सात्वहूंश्वत्रियायियि॥आज्ञाय
मनयूवृक्ष्ध्यमाक्षमधियायूकि॥त्वंयरूग्रेनिरुनरूत्यीयाउंमयत्वाहूंही॥ • ॥त्यायगक्षावध्वनि
क्षुदाविरुज्ञनयाद्वनयूनरुवियकावयायवडयवायायानिमिरुनयर्व्वं॥ ॥रुथवाकं॥र

ि श्वक्व वोक्ष मायवस्नुश्रव श्वनंम्रु श्राविद्रस्यायश्वियश्वंनिवृतस्तु व्दिमोयर्थं॥ ॥जायस्व र्न:
र्यं श्राक्लावि वां॥स्याकोक्लियूपत्क्ष्विश्रुविवंयानश्वियक्ल वंदविक्षयात्वस्वव श्वनवक्लयावविद्यायाका:
श्रीमना॥येना श्वंश्ववस्मा श्राविनवाक्ष्वक्लयाव पूनाडाय श्वित्रास्मवयाक्षायेदवनिवागीया: १८
नवावायक्लवाय्यश्वव नाश्वंश्ववं॥ ॥यावश्रीमिक्लियक्ष्वानंदीनेयमत्वनूयवा निवानि॥याव स्वश
यया त्रव वक्षानंवा श्वेर्यावितू॥ ॰ ॥विययवस्नुश्रायांडयक्ष्वावस्याद्विस्थायान वाववनवायो॥

याक्ल्वायंयाद्वायानश्वयानस्मावडद्धिमश्वाय॥ ॥मदयायवस्माला मवस्नुविवानमिवंयू
न॥ ॰ ॥श्ववतत्रमाययूयविवस्रानयावश्वमवश्वक्षवक्षनवावयाश्ववा॥ ॥वश्वायावदक्षी
स्मालूं युविगक्लिसवश्ववव॥मावस्मवायंवनिमयंयवायद्वंगमक्लमवं॥ ॥थश्चयायुया:
वश्वनद्दावमावक्ष्वयया द्वयूश्ववश्वीववमवायंवमक्वादवश्वाहावस्वमम्रुवं॥ ॥लामदमू:
क्ष्य्ययामिविक्षानवं॥शनवूयवगयमायाश्रुक्षश्रुक्षवाप्रुविक्लवश्च॥ ॥श्वश्वमयुयंक्लमावावा व्य:

वाचंवा सज्ञान थवा यधवीं म वमावव ढाव वानदा यावविक्रवयरं॥ ॥ धनधर्म्मेगास्कं यथ्वनिदि
व्वारधं नवा मिववाश्वयनंदु वाल्मनक्षास्व गादनवाज्ञनथ्वावियाश्वेम यथ्वायज्ञ याम थुवंगवाय:
यथ्व॥ ॥ धर्म्मेगास्कयाठ्यागमसमत्वंथ्ववस्वगावद वाश्रायाश्च नन्यमद्व मखांस्व गाव मूवया १९
याव थ्वादिन नव णयास्व गावयाढ्रुउन दूयु मथ्ये व थ्वकाश्चंथवं॥ ॥ किश्रा॥श्रव याद्वियावि:
वानांढ्स्मि स्मान मिवक्रिया॥ दूर्ष्के गाम वधयाय सानं गाव भंकेयाविना॥ ० ॥ इन्द्रिय निग्र:

ढ्याय मढ्व याधर्म्म ढस्मियास्नान थ्वं आधनढ्याव थ्यथथ्वनंद ग्मा स्त्रीया आ गवधर्थं मा
स्कवधवनयमढ्यवं क्रियामवाम्म याह्मानश्नावायीधवं॥ ॥ गम्मया ढ्व वंनश्रमांय:
ढत्रमावाम्मवा विश्वामस्त्रानथ्व॥ ॥ थ्वजिनयाहामजिवथ्वविश्वामनवादावधवं थथ्या:
श्रनविक्रवयवं॥ ॥ मथ्वस्याढियविक्रावस्थ गाव वंनवधयुणा॥४॥ अभिषेकादि गुणा स्वा ये:
स्वगावमूर्द्धि ढकेन॥ ॥ गथ्वश्रवमा समस्कयाय विक्रास्वयगुणवकद्रावसात्वंस्वगा:

वस्मयग्याचिंदंयुनवक्कज्ञवसम्यंथवम्माकावममपुकावस्मयाउनल्हाकवाववयिव॥ ॥
ङ्कंकिविन्ह्यनेवासायाययविव॥ ॥थथ्थविक्वयावकुंद्वेयाद्युनथमनस्युस्याद्दावकर्सं॥
॥अप्राह्नंवधीमिवाक्वनस्युउत्ताकनख्याविंक्ष॥ ॥ववयुनियावाज्ञानववयुनिय॰ १०
निह्नामंधूाकाथ्वं[?]मिञ्जिक्वयरूवधवं॥ ॥कत्त्वेथ्थविवायिमंनवाकेयां॥ ॥थ्थवन
थूवस्यनेविवाव्रमयास्यंज्ञनवनमम्नवधवं॥ ॥नथ्याकांञामजिवंह्लमन्नमाविवज्ञाथः

सत्तःमसासिकांस्त्रीहुयाविसमविवथ्यामविन्ह्यवाक्कंमविवायथियक्कुंमंमवीयवात्नयिनयाः
किविक्रियां॥ ० ॥गथ्थ्यावसा।किनवंकीनवंक्तीह्लुवनवंनयाअन्नविवक्लधक्मनिवायथ
मविनवंसासवयंवैकयाक्ष्रीकिनवंगवायादंकयावाज्ञाविंक्वयंज्ञ्ययावक्कननिवृथयादे
यानवायेंश्वकना।मावारवद्दनंमकिथमह्नावधवं॥ ॥तवक्कुवावकथ्विताथ्याकथ्यास्द
थ्यूडवाव॥ ० ॥थ्थथवाज्ञावक्मूनिश्वयाद्दवायथ्यिनंवथ्युनिनअूदंवावमथ्यावं॥

॥ आदिमूर्त्तये ॥ ० ॥ सुमेरुकूटवपुषे ॥ ॥ इन्द्रनीलवर्णवर्णाय मायाजालाकृतये ॥ सर्वे-
न्द्रियाधिवासाय ज्ञानमयवपुषे नमः ॥ ॥ बुद्धमार्गप्रदायकाय ज्ञानदेहाय धर्मायतनाय
बुद्धमंडलसमन्तानिरूपयाकारसमायताय कुसुमवपुषे ॥ ॥ येनशासनं सर्वसत्त्वानां २१
न्मनयानन्द करणाय निर्वृतिमार्गप्रकाशाय त्रिविक्रमाय धर्मरूपधारिणे ॥ ० ॥ समन्तसंस्थायाः
द्युतिमानमयनमः संस्थाय चन्द्रावलोकनाय समस्तरश्मिवपुषे ॥ ॥ नमस्तथागते ॥ः

श्रीस्वयम्भुनिर्वाणमुत्तरकायधर्मानिर्वाणकायवज्राय धीमतः पुनरुत्थानाय नमः ॥ ॥
गन्धर्वनमस्कृताय गन्धर्वाय नमः सुरासुरनमस्कृताय ब्रह्मविष्णुमहेश्वरसंस्थायाः ब्रह्मनमस्कृताय
नमस्ते बुद्धाय ज्ञानमूर्तये सर्वधर्मपारगाय ॥ ॥ सत्त्वानामन्तकाय बोधिसत्त्वाय नमः ॥ ॥
धर्मधातुस्वभावाय समस्तवरकुशलनिधानाय विराजमानाय नमः ॥ ॥ यत्र सर्वसमन्तभद्रादिभिः
ध्यायन्ति बुद्धाः सर्वसत्त्वानां धर्मनिकायाः सिद्धिश्च ज्ञानकर्मादिमाः ॥ ॥ यत्र धर्मा

२२

नगुवित्रदिवगुवमामयवावसवावयवतसवीवकुयंयवां॥ ॥ वश्वयवेकु॥ाववधूयविः
यन्नानां मायवूद्वे वर्वेन्न सधानल्वीयायविवानं यस्नुयालोंनयस्थिकथाविपल्लावववविसयधवावा
यूयूमस्ववकुदी॥नदूधश्येमवलंश्यविवानाधिस्यवां॥ ० ॥वियमिमयं स्वं दवयंसस्यवा॥ २२
यूयूयनत्वमधवनवीश्यवादूयाविवानविकुवयवां॥ ॥ वेकु॥ावियमिश्चेश्यमथायुदय
स्वमामदमिवाशीदूनाष्यूविधिकमश्वायेमामिवारिनवियश्वनगुश्रीयस्वाविमिद्धिमिदेद्विमदालाम्मः

वां॥ ० ॥वियामिमधीश्येवकुर्मसंयदमवामावकुर्मसामामयदूनवववनल्लायसवकुसंयामय
मवकुर्मयेमनायवांस्युयावाकुनानागश्वःमसदूवगादकुधकुर्मदालामायूयूयसमसकुंमकुवा॥ ॥ वा
युयवकु॥ यस्वावा४यूयूयेह्मविल्लानयायरूतीमिस्तूवां॥निरावन्ताहूंश्वाथमावयांधीयमकुकोवा॥
० ॥गाथ्वधावमायूनावायमनयानवाउवमावकुकावयंसरिवायश्ययवकुवसानानंथवावकुंदुयः
ववमज्ञयूद्धनवानमायांमभायांश्यायववमवायथुसामीत्रयदीयमकुवाश्वयूवाधवां४॥ ॥ ०६ःः

दर्मिं इच्छवत्रियवाँ॥ ० ॥ञ्त्रवमनस्यंथलूयायघता॥ ॥सर्वे रवावितिँउयज्ञाननमिदम

यद्धियवाँ॥ • ॥ष्टक्रवानन्मं नन्नाविळेयाद्द थ्रयास्त्व वस्याद्दं वास्यवनगुनमवँ॥ ॥र्येम

श्वात्र्स्यानानमवियिक्ष्वनाँ मंद्दवि स्वायमाधिमा॥ रद्रवगुंछलमायनवञ्चछमऌवद्धिनछ॥ ॥

विक्रयवथिमत्रदिक्ष्वयुरमनवदवबवाथ्येयावद्दवमाभायेभावमाघावनगुनम्वलेंदतत्रादः

कमनच्यवँ मळे द्वशिवं स्यवजिवँ॥ ॥ड्डनिमींविच्छयिक्षिमस्मक्त्तानमायाःच्चविमाळ॥

॥थ्यथविक्रवयावसाममक्नवयपृतिँयागवलव्याद्दसमवस्यंपूनामगवलञ्चस्यंमाराँ॥ ॥

अनक्रवँसयाथ्याद्वलावायनावाँ संनवलाक्रयश्वाअवभासिक्रयञ्च॥ • ॥थ्यनविथंञ्चमवः

वम यानलाथसीश्च्वानथ्धनवलीवलीवञ्चाद्दनबावविक्रयवाँ॥ ॥सिंह्लमाछ्द्दवद्दवक्रिः

मज्ञालंममावि द्दं गमामाश्चाथेवछउनियाविज्याक्रनवनायच्छिमनवा॥ • ॥समनकंउवाद्वंमावः

मृहंज्ञयागवावावँयवाद्दयच्छियनिक्वविद्दववदाक्रवगासवायूथवाँ॥ ॥वनमथ्यच्छायिँयः

यामिमिञाङ्कयु थ्याक्षानिङ्कलव ॥ ॥ थ्वनलिमिनङुस्वमजिस्यर्वंदावथ्वमवनिलासजली
दावं ॥ ॥ नूथ्वबंयाङुकमवलाश्च्युःवयामाडवु ४ ॥ ॥ सबलनिलावढ्स्वदावबवथ्वनि
यनिस्यंथ्वबं ॥ ॥ किंमिवानीमूविबं ॥ ० ॥ थ्यावथ्वयामङ्कनगथ्वबबं ॥ ॥ थ्विनथ्वीवङ २३
वाय ॥ ० ॥ थ्विनगीवमङ्गावनयुमिनथ्वब ॥ ॥ मामामिकंथ्विनावनिस्वनावविनयंदिकं
काग्रीवावनक्तथ्वाथ्वकयन्हिदिनवुह्रियथ ४ ॥ ० ॥ मामनवुथ्वनस्वनावथ्वस्वकावानियादिनयाय

थ्वकथ्वावकिनथ्वावमनम्तीदिकङ्कयु थमयामवाय्येयदान मवनयायु थ्वमहिनयावसामवनंः
हिनयायुव ॥ ॥ नदस्वामिमबंदिवथ्यंकनाम मूस्वावाथ्युबीमिव विवबनानिवमञ्जि ॥ वाडु
स्मावंयाथ्यंथ्युल्यानि ॥ ४ ॥ थ्वनन्ङमित्र ढवयाकानामथ्वु गथ्युवीयानिवमविवबनसवमवयं
वाद्थ्वनममयाथ्यङ्कविवथ्यवं ॥ ॥ ङ्क्यालाङ्कमथ्वेवंदिवयकमसमीयङ्गवा ॥ ॥ थ्वथ्वनी
नयावमकयाहिवथ्यवाथ्यु वावाथ्वसंवन ॥ ॥ हिवथ्यवाथ्वनङ्गसवेदायायसंवनयाणनः

[illegible] [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

सर्वविभवत्॥ ० ॥ दक्षमित्रविजयीव [illegible] ॥ ॥ विजयीवावदत्

मित्रविभवत्॥ [illegible] ॥ ० ॥ विजयीवनधाव॥ मित्र [illegible]

[illegible] ॥ ॥ [illegible]

[illegible] ॥ ० ॥ [illegible]

[illegible] ॥ ॥

[illegible] विजयी [illegible] ॥ ० ॥ [illegible] विजयी [illegible]

[illegible] ॥ ॥ विजयी [illegible] ॥ ० ॥ विजयी

[illegible] ॥ ॥

[illegible] ॥ ० ॥

[illegible] ॥ ॥ [illegible]

नस्तु ढङ्किमावहुवकःयागाह्निनयाव। तदक्वव स्वथगथ्यामजयानसियागाहुत्यामि॥ ० वक्विना

गावामङ्ग्ववंहाथू यागतिक्वन थ्वनविथाछिगथ्वनकुवासं यागहुवेनथ्वाथ्ववं॥ वक्विवगीवा:

ह्ववदगु॥ अस्यावंविन्तु यथ्वगक्वोयामकयवाव थ्वनथ्वयनया॥ ० वक्विवगीवनथ्वाथ्वखुनदक्वान: २८

दयवाजांय्ववथ्व स्वथनुक्वनमाथ्वंगथ्वनवावथों थ्वयनिवानि यागक्वविनथ्ववं॥ वक्विवथ्वथी

नाक्वं॥ अमथ्वयवियावान यवाजीवानांवक्वधंवंनिविवि थ्वनथ्ववगं॥ ० वक्विवथ्ववनथ्वावथ्वव

छिवमाववं थ्वयथ्ववव वक्ववथ नीविसंनया नीविसंनवाव॥ नीविसंक्वा यामदाथ्ववं॥ वय:

वठाथ्वायदाथेथ्वनंवक्वहावावक्वाक्वनयथी॥ अमानंथ्वकवंवक्वादेवथीथनवथी॥ ० वग:

थ्वथ्वनमा॥ अयनवाति यावावथ्वंथ्वनवक्वाथ्वहुवयमाव थ्वनयासिंमल थ्वीवक्वनयथेमावथ्व

यासिथ्वंथवक्वामानवगवक्वायाढक्वमाव॥ वथ्वयवक्व॥ थ्वमाथेवाभमाथ्वाकंयामाक्वमं:

स्थिवहुवथ्वा॥ कीनिथ्वमाविनढवावथ्वमाथ्विनयक्विवं॥ वगथ्वथ्वावमा थ्वमेक्षथेवामः

माक्व थ्वयात थ्वन त्रुमा सवावदव त्रुमा मा माव दाव थ्वत्रुदिन सम सँ माक त्रुमाव द्वाया द व
माव थ्व द दव॥ ॥ विस त्रीवाथ्वव दत्॥ मथ्वनी ति माव द्या दक्षव विद्व द मार्थी मानाम्वक्ष्यं
माहूमदमममथ्वेम॥ ॰ ॥ विसत्रीवनज्ञाम॥ मामिन नीविवाग्रमथ्वयव ब्रुथ्वनं थ्वक्मा मागयया २६
द्यानदावदक्ष्यमावक्म मदन दावथ्वथ्वव॥ ॥ अथ्वव थ्व॥ थ्वनानिज्ञीविम थ्वेयव॥ थ्याक्ष्यत्र
ज्ञत्॥ यानिमिले व वंथ्वया॥ विनाश्चनियममवि॥ ॰ ॥ थ्वयमयवज्ञमाथ्वावथ्वादक्ष॥ ॥

जाकि थ्वगुना नाक साथ्व मथ्वा म संया मद॥ मथ्व थ्व दल व दि व दाक्ति क्ष विथ्व मि॥ ॥ अथ्वथ्व
विनावलेयमवन नकज्ञ निमम क्षिवाकथ्वयाम थ्वयना विजि थ्वयिना थ्वनथ्विमां॥ ॰ ॥ मथ्वथ्व
वमाज्ञनथ्वविथ्यांमदवज्ञ॥ वमीमावमव थ्वयनिथ्यं थ्वन ज्ञ थ्वव त्रुगमा वम थ्व थ्वयनिव क्ष वयथ
वव त्रुगयया दवादयनिथ्वावक्षथ्वव॥ ॥ विकं॥ माज्ञमज्ञयूवीयास्ति निम्बिन मनयूज्ञन॥ वि
नथ्व वनवाथ्या सयथ्व क्षयान यमिजम॥ ॰ ॥ ना याथीयास थ्वजन निम्बिनया दनया गमीज्ञूज्ञ

स्त्रवमाँथथिँडमसवालँवायमक्षषविठँयक्षयथिँयावयत्यमालसमित्रथवं॥ ॥यथ्वा॥यदिनि

त्यमानिथ्यन निश्चलंवालवादिना॥यषक्वायनवरक्षकवन्नलखंरथवलवं॥ ० ॥नदवालंथथिवः

मवश्वायीगयीउथथिदगविदगयक्षीखिमयाकवावजुम्यावायायावायीथ्यु येमवायंमदवडवमवव॥ १०

श्चायावंमथ॥ ॥येमराषवीवसुधानाक्षचुयमत्यक्षनक्षंगवावंग्रधविधीसिठवान्यानक्षां

यिनासुद्राथ॥ ० ॥गवीवसुनवसुनिश्वक्षवयावक्षवीवक्षवस्वमाजुनमायूनसुनद्वावंवः

स्यान्कवंमगाव॥ ॥ह्रुत्याक्षीदिवथ्यवडयक्षयमनानयवक्षकस्यान्नवाव॥साधुमित्रसाधु॥

० ॥थत्यविवगीवनक्षायादवावदिवथ्यवआनक्षयावआयायमाननक्षावंगमित्रसाधुसा

धुसूधवं॥ ॥अननागिमांनावाक्षयक्षवंनाथ्यायायिवसुवंवयियज्ञवो॥ ० ॥नरामिवदि

तगीवमथ्वयवावमघूनथवक्षआधिनयादवादयनिरक्षवपंवनयिगासमनवंलाथ्वयाक्षामीः

ह्रस्त्राविक्ष्वमानंस्थूयूजवस्थिवधवं॥ ॥तवमुक्षाखक्षयांवध्वनानिवनह्निमानि॥ ० ॥ध्वव

स्वयाव दि व थ्य व्का मान म व व गं य ग रु व ॥ ॥ द्धि व थ्य व ४ मनो आदव्वं स स्यु ज्या द्ध ॥ ॥ स्
दि व थ्य वा न व वि त यो व य र वि न म म स्क व व स्यु सिं य थ्य ग का न आ व म ग यू ज्ञ व यं मा य या मा द व ध्य रं
॥ व म स्व वि त यो व म स्वे थ्या व्र ना न व श्व न यि ल्ल म व मा ग श्या अं म स्व व ङ्क न व ल्या ४ ॥ ॰ ॥ स नि ३१
न वि त यो व स्र व यं थ्य या ग न श्वा ठ या थ व स्वा ला या न स्र न ध व कं व य न या य म व व ॥ ॥ यि व ४
॥ या थि वा या ज्ञ न श वा स्य ग ज्ञी स्का मि यं म ग ४ म न व या स्व वा ल न्तु या ग व श्व न य स्थ वि ॥ ॰ ॥

ग थ्य श्वा र मा ग व स्थि या ज्ञ न न वं दा यं वा यं ज्ञा डा य श्वो न यु थि म वा स्य ठी ठ य स्ग स्व न थ यिं स्व स्म न दे:
व न द्व या या म या ग स्कु यं न या म व्य यं व श्व न वा म ध्व कं ॥ ॥ स्र यि वा स्य ङ्गि दि वा व्र म या या द्व यो उ
नं ग ज्ञ रु ज्ञ स्कु म या व यि व श्व नं ॥ म वि म मा ङ्क वि ला स्त्रा द वि ड मा वि थि व द्दा व ल्ल वा न्नि वि म म वि ४ ॥
॥ व न्तु म स्यो थिं यू वा श्व न या म या द यो ता वि रं वि सि थिं यू म स्यो थिं यू व व व ङ्क गी य व द्व व श्व न वा द्व
द न ह्मा नि व व श्व य म दु दे व व व व व व ङ्क दे व न स्व या मे श्वा ह्मा नि स्क न थ म ज्ञ व वि वा श्व य म श्वा म म

स्म्यासिंहववववक्त्रधवां ॥ ॥ श्रूयव ज्ञानेवाक्षविन्दविघ्नायिविदुगमध्मंत्राग्नबन्धायदुः
वद्यह्मनियूनेवगारुङ्गनिलानमल्याक्षसमन्द्रादायि ॥ दूनीवसूविमस्कविंस्पुपविवंवक्ष्मनलाव
गुप्ताक्ष ॥ बावाद्दियमनक्षमुगाविनवायाद्वानिदूवादयि ॥ ङ्कवियवाश्वाविथ्यंक्ष्मवालिंमविः
वृत्रीवयस्थपिवक्ष ॥ मयविवायास्यदूदगायसी ॥ ॥ थ्यवाक्ष्माद्दिवगथवानविवृत्रीववाः
धवसाब्द्यविक्ष्यादावज्ञालिंगवर्वं विक्षप्रीवयग्वंथनविवृत्रीववामक्षधववयग्नितविसर्वंः

हूं२

थमथक्षयायादुमगवर्नां ॥ ॥ द्दिवयाक्ष्मविववंयविमूक्ष ॥ ० ॥ द्दियग्रवाथवक्ष्मुग्यावंदूनावं
॥ ~ १ ॥ ० ॥ स्थावयूयवानवावि सर्वंद्रुकाकंवंगीवाग्धयसिदवाह ॥ ॥ थ्यनविथ्यमसम्म
यूकाकंमासांवादलयूयवानवक्षा यवग्नविवीऽवावासंधाव ॥ ॥ द्दम्मद्दियग्यवग्राग्यासि
॥ ॥ गथिंपद्दिवग्यवमनायुनबद्ध ॥ ॥ श्रुत्वाहमयिनयासादनक्षीमिग्धमि ॥ कवामं
मद्धनानूयक्तीऽमर्दिसा ॥ ० ॥ स्कवक्ष्वनमिवयायवांग्यांयोग्रथजनजवामिग्रवंयक्ष याक्ष्मनध्य

११

नंथ्यासम्य मञ्चदङ्गयायामियसम्यवथ्यवविश्व्यावनाङ्कवसथ्यांनावावंथ्याध्युङ्कलिनामग्रेयाद॰
काय्यवयवावयसवयंवाद॥ ॥सयवमृयाङ्श्वङ्गयायविज्ञाम्यगृम्ह्वाङ्कगुनामवक्षावन्नाविन॥
॥ध्वमृमनथवङ्गय्यनत्रमवयंक्रयावयुम्हाङ्कवद्वयाद्वांयुजम्बुकनयवना॥ मवमा १४
लाख्वाविक्कयदसी॥ आवथमस्थमात्संयललिनंकञ्छ्यामि॥ ॥थ्वयवाम्दावजम्बुकनवि
कुवयवं॥ गथिंयुथ्वयवायायावासयुर्ववनकिंयुवा मथ्यनयथ्वं॥ ॥कुथवउविस्यासंनाः

वद्वयानयामि॥ इस्यालाख्वायसम्यावदीक्॥ ॰ ॥आवयाथवथ्वाविथ्रुमयावयक्यविमा
ननि भायथ्वं थ्वथ्वविक्कयाव सयाविदायवाद्वावथ्वाव॥ ॥निरक्षवक्क॥ ॥सामिव:
क्रगवज्ञवयाथ्वं॥ ॥मकुगा॥ ॥वनॅसमायघुसिवन्हं॥ ॥सुवानथ्वावयावनन्दवायाजु
मथ्वं॥ ॥जम्बुकाद्कुगा॥ ॥कुदवुद्धिनामजंवुकाद्दुं मवथुरुवधुद्धीनांसुवन्ह्यामि॥
॥जम्बुकनथ्वावकुदवुद्धिनामजंवुकजु थ्ववनसवांथ्वयमथ्यनासिवयाद्वाथ्वयायथ्वं॥ ॥

क्षुस्वानिं ह्वों मित्र मामाख्य पुनस्सबन्धुर्जीवल्लोकं प्रविष्टोस्मि॥ ॥थ्व आव छं मित्र नायबाव बन्धुज्ञ्व नङ्गस्यायाः ह्नावाव गृहस्थिं युव छ्वव द्वाध्वं॥ ॥अधुना तवानुचरेन मया भवितव्यं॥ ॥आव छन्त अनुचर जुयाव च्वने स्वं॥ ॥ततः पश्चादस्तङ्गते भगवति मरीचिमालिनि मृगस्य ९ंग
वासभूमिं गतौ॥ ॰ ॥थ्व थ्व सन्ध्या यंव रुगवरु आदित्य बीं ग्य सूर्य्य वन वा थाय मृगया वासस्थाय
समनङ्गं वनं॥ ॥तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं वसति॥ ॰ ॥अथ्वज

स्वव वनाय मृगया वासस्थन रुगया मित्र सुबुद्धि नाम्या व क्षुस्वान चिमामखानं॥ ॥तौ दृष्ट्वावदत्॥ ॥चि
त्रव नश्चाव॥ ॥सखे चित्रं मृग कोयं द्वितीयः॥ ॥सखा मित्र मृग अभायामा मध्वं॥
॥मृगो ब्रूते॥ जम्बुकोयं अस्मत्सख्यमिच्छन्नागतः॥ ॥मृगन धाव जम्बुक नं ज्व मित्र याय
यस्यं वस्ध्वं॥ ॥काको ब्रूते॥ नयस्य आगन्तुना सह विश्वासो न युक्तः॥ ॥काकन धाव स्वामि
कत्‌ भाव विश्वास याय मसिद्ध्वं॥ ॥तथा चोक्तं॥ अज्ञातकुलशीलस्य वासो देयो न कस्यचित्॥

माङ्गीरस्यान्द्विबाध्यनक्वमागृङ्गाजवङ्गवथ॥ ॥गथ्यवथ्यवमा॥ञ्जालगीनथ्यवन्तावममस्यान्त्र वामविय

मर्त्तवरानिवामविमावशजलङ्गवयृतरानियावावलमथ्यममाव दवस॥ ॥तावाद्लुथ॥वथमन ३६

न्‌॥ • ॥स्रृयनथ्यवग्रमास्वगथ्यथर्वां॥ ॥वावश्वथ्ययावि॥ ॥क्वायलनन्ताव॥ ॥व्यामि:

यागिनथिवयृत्वाहनामयथ्वबं॥ममानयक्वोठीश्टथ॥ ॥यामाद्विवंदलमागक्ष्मीवयामानियमागृ

दवृहनामयथ्ववमामवथरृश्रृक्वीठीमिमाथ्तुमादव॥ ॥कमावथाहवर्थ्ववसुविथाङ्गनितनयनी:

दवङ्गवानामयृङ्गर्यामिवमाति॥ • ॥थ्वसिमायावामर्हवयावनाममायृथ्वजनाङ्गवनामयृङ्गवमुङ्क:

वमववंथायृ॥ ॥मज्ञीयनायवथ्वपवामीनथ्यथ्विवश्थ्वानायनु भीविवििवदवाति॥ • ॥

थ्वयावथ्याथ्येथ्रथ्वसिमारावमवयंवायृ यथ्वियनिम्यंग्रादावविनायविनायवियावनर॥

॥मनामीजीयनि॥ ॥थ्वनभ्राथ्यायथ्ययाङ्गथ्वादावयानं॥ ॥अथ्यवमानिद्दायवाशुनाममाज्ञाव:

श्यथ्विमायवीवाङ्कवायिथुंवनाववथ॥ • ॥थ्वनतीथ्यङ्गमयायथ्यावमानीयवथ्रुनामरुविनय:

क्षियाराकानयथ्याहुथ्वथ्याथ्यमवनं॥ ॥नमायाकंडस्थ्र॥ नवर्को हयाकुल्तिजं ध्वानाह्नवस्थ्रनाथ॥
॥थ्वकतिननयव्द्वानयंस्रवाकाडस्रानन्हावं॥ ॥नस्कुन्वाजतन्नवनाकं॥ ॥वोदुयंमायाक॥
॥थ्वथ्वमगनवाकादायसायवायावजनक्कवपुरुदथ्वावयावयवं॥ ॥दीयीवकथ्वथ्यनमः ३८
वला थ्वाकमरयंदादानाक्कथ्वाथुनाविसानिथ्वानयवायनमयाणक्वानुस्थ्रान्॥ ॥कीयीकथ्वीम
यावथ्रथ्वक्कथ्वादावक्कथ्वायममायाथ्वर्वं थ्वयमक्कयावथ्वयासमियमंयान॥ ॥कथ्रथ्वायाक्वः

थ्वंकवल्लनकुसमियमवगङ्गमिथ्यालाथ्वायस्थ्यावकीन्॥ ॥थ्वथ्वायकमिनथ्वयासमि
यमवननाथ्ववनायवायथ्वर्वाविकवयावथ्वयासमियवदावथ्वाव॥ ॥थ्वाथिलामकिवथ्व॥
॥कतिनथ्वावमायुवानमक्वावथ्वर्वा॥ ॥गुहावदनिकस्रं॥ ॥गुहेनथ्वावकुमथ्व
यं॥ ॥मावकीन्॥माङ्गिवर्ह॥ ॥यीयीकथुनथ्वायजकविथ्वर्वा॥ ॥गुहाव॥म॥नः
थ्वयमावकुयंनायवकक्याङमिमया॥ ॥गुडनथ्वावथ्वमथ्वाजवसाजुदिवथ्वथ्यकायिनर्नः

ह्स्वतास्यं त्रमावश्यामतवतावर्त्तं॥ ॥माज्ञोवायदलि॥ ग्रयतांनावतमवतनं॥ ॥कलि
नध्यवज्रवयननिह्नवावर्त्तं॥ ॥श्याद्वदं यदिवश्यस्कतदंवयं॥ ॥ध्यवमङ्गनमावतवमी ३८
मावश्यावर्त्तं॥ ॥यनथजातिमाकणवाघ्रिनिंदग्यनयुयनांतविता॥ श्यवदावंयविह्यायव
वध्यवृह्यायवातद्रा॥ ० ॥गश्यश्यवमाजातिमाकरमहवमवंमावश्यावायुत्रवयावावयोग
वतावमायावश्लुजायुहवडायज्ञव यायायुह्रवशामांहयायायमावनजापनवमावंश्ययायः

ध वं॥ ॥युह्लाहृवदत्॥वाथंतवानृवरितं॥ ॥युहृवमशवयूतमजाकवरितगणवर्त्तं॥
॥माहृवयात्॥द्वीर्यवक्षनध्यव॥ ॥नुहमरुयांगाकीत निताह्नायिनीवामियाव
ह्ययोवाह्रायनतिह्यामिववि वंत्रवं॥ ॥थ्वैर्जे गंया॥वीयम नितह्मानयाद्वावनीयामः
मियाद्रह्मवयोववयंवाह्रायनत्रमवयावताह्न॥ ॥यृह्माघ्रवश्मीह्रान ममविश्वमः
ह्रमयां॥यह्लिलामममायुयह्लवह्नि ह्रमाकवह्ना वियावह्लश्या धर्मह्लारुं मदमत्रायात्॥

॥ स्तुध मोह्मान गास्त सवध्वं जनविध्न सयाव यस्त्रियनिर्यं जन्दवनस्तुयसंमाज्ञाव धवनस्तुध

मोशास्त सवस्तु वधमोशास्त स्तननविद्याम वयधवं द्दवनस्तुथनवया ॥ ॥ तयवस्तु ग्रत्नाद्दगाध

मोह्मायत्यामाकिथिंद्न्तु मथ्यवां ॥ गृद्द स्तुध मोशियया ॥ आयावयधूविवंवाय यि माकिथ्यं गृद्द मायमांया ॥ स्तु ४

सुयाध्रयमां सुयां नायसंद्द वनमम ॥ • ॥ तत्थस्वा ॥ यद्दान कवाकित यायौकनवयमा ॥ यिनावनाकि:

थियुथ्यां ॥ ॥ थवस्तुमस्तुमांमद्दनसत्वं यौ यकिववननयिवंस्तुकिथियूनायाय ॥ ॥ तथ्यव ३८

कं ॥ हल्मानिस्तु मिवृद्ध्वं वाज्ञ स्तुथिविंमस्तुणी ॥ तका ध्रयिसवां गद्दना ॥ स्त्रियजवायस्तनी ॥ • वद्द

वथ्यं मावयावंनयिनं वाय्यथायस्तुस्तुमिथनदिसनथवं ध्रावनह्माद्मावववनवंध्य आदिनसयि

माववाय्यवं धयामा ॥ ख्रिवं सर्द्धयायागृद्धस मैय्यवनं मद्दयमस्त्रव ॥ ॥ तयवस्तु ॥ निवृत्तय

यिमल्लयू स्याक्रवद्धि साह्विवस्थानद्दिंसंद्द ववयाङ्मास्तां वद्दुध्वाद्धवनवगानि ॥ • ॥ निवृह्नक्मवः

स्तवसत्वं माधूजननद्दयायामयुमाथ्यंधाववमा ॥ ज्ञायुमवाणवद्दुमासं वृद्धाववयागृद्धसकयंसम

स्कं गुह्यया द्वय व थवाग्वं यवं॥ ॥ गुह्य वदरु॥ मात्रौ वाह्निमाग्व रु वय॥ यक्ष्मिगा व वाग्व त्र
निवसक्षि॥ वतेवं व्रविमि॥ ॥ गुह्य नथाव॥ स्कूरुपूव वक्षिवामय व व द्वक्ष यक्षिया वा वाच
मिमामत्र व म व यंवा गुथवत यश्रुक्षा वाय वं॥ ॥ माज्ञौवाऊ मियष्ठाव ध्रैस्युमाविकूर्ण॥ ४०
॥ कृकिन यिवि थिया व क्षमयाक थियाय व्यारी॥ ॥ मयाव वर्षमैशम्भुं गुन्हा वीवि वाय गद्
स्कूवत्र व मिदम स्वव मीवा॥ ॰ ॥ ज्ञैनधर्म्म गास्तु द्वाव निशाकनदू क्षाव व वत्र व तलयंवाव॥

ध्वकं॥ ॥ यतः॥ यवस्य वंवि व द्वमानानां मयिय्रु मात्र श्मस्त्रा गमाह्लि स्माय व माधर्म्मः॥ प्यजेव
मर्त्यं॥ ॥ यवस्य व नाना गामस्त्र सह्मा स्यंवया स्थू यामिं वं गृह्नि स्माय व मश्व मैवव वं श्वमय
ध्वकं॥ ॥ स्तुयवक्र॥ सद्मा ह्निमा निश्चै ह्मा व व वा ॥ सवैसत्ताध्य या॥ सवैध्याग यरुजा गुंवत
वास्वेनाषाक्षित॥ ॥ स्नुयवक्रा॥ नव्रा न जड्स्वनि श्वम यथनु यामियस्मा गवि व गसमांना
गंमत्वे मस्थ्र जयाय्रुमि॥ ॥ वीक्र॥ याक्तियस्थू यवता नासमकथ्याठ यश्र जाकवं॥ एकयंक्षा मिवा

श्रीत्रिबन्धस्याश्चेविमूयवा॥ ॥वानननक्षवयाथवनश्वनिम्नसं ग्रवक आदिवायावानवम्नः
याश्वनवाबमखवाश्ववम्नयायाग्रमाबा॥ ॥अयवक्ष॥मूलयमिावेयदुःखं मूबूवस्यायः
श्वायवा॥गश्वास्वननुमानस्य यवाथियवियश्चिर्दु॥ ॥मियवयायायवह्रयागयादुःखवयु ४१
नांमयाश्चस्नमानवधवःक्षनठनयमवनमावयवकठावयमवक्षलयमाल॥ ॥स्वसूक्ष्व
नजावानगाथानाविययुग्याबा॥ग्रयदम्मदवस्याद्येवाव्रश्रीयावसंज्ञनः॥ ॥थमयूथमव

नाक्षवयाग्रायवयु स्नामयावनसर्यं ग्यवथंदग्मवथथिंग्याग्रनथंनस्त्रीश्चीवनवाबदग्मदवयानि
मिलनमवयायामश्वास्यं मदायागवमननानयायुव॥ ॥सर्वविख्यायवबक्षाटवाद्भनः॥
नमादिनयूयसूलयश्चिमावबानाउग्यवग्रानियग्यादवि॥ ॥श्वयवावक्षथमवम्भिषंदः
नर्क्षविश्वयावर्वार्थवबलूकवि॥ममावामवानंश्वनविश्चे मंगावमदूमायाव मंगवामावायाः
वसिमावासनयवतं॥ ॥अश्वयमांमयव्यानिस्वादिवानिस्वेः॥श्रमवाल्लेः॥विवयाद्धिजे

ह्लासागालक्वां॥ ॰ ॥थ्वनलिथुं यामह्रयंह्नि यामायाभानस्यावमावडाह्मयोंह्नि ह्ना॥वयाद्यावदु४
ख्यियाद्वविलायद्याहविह्मवयवं॥ ॥यविह्लायमाह्नेवेवोठयाह्नितिसुलयवायिम४॥ ॥थ्व
यंह्नियनिस्यं माचामामायावसाकयाढंमालयाढंववस्यावकविलसिमाह्वावावकंद्वव॥ ॥ ४२
ङ्गंकस्हनावृयथह्नि४वकवनूचाकवसास्वाह्नितियाह्यानि॥ ॥थ्वयोंह्नियनिस्यं मालसाः
वयोंविह्मवयंमवह्मथ्वायसमावज्ञालदंसांथमथमवाह्मयासिमायाचसंमावामासवासख्वः

नं॥ ॥थ्रुनह्मवखानन ञावचा४ख्यादिवा४ङ्गंसिनिस्थियह्नि कि४मवकंज्ञलासपृथ्वाया:
याविव४॥ ॰ ॥थ्वथहनायद्धावथ्वपुद्वनर्थंभज्ञमवावावालवथ्वदेथ्वथवावयं यह्नियनिम
ववयं पृथ्वयाव॥ ॥थ्रुवाहुंववीमिाथ्रुह्लवकवलगीनख्यादि×॥ ॥मवहिवाख्वन
पुगह्लाव थ्वभनह्मवगीलथमसमियाह्मवासाविययवकस्थवं॥ ॥ङ्गंख्यावह्नीज्ञपुवासवा
यमाद॥ ॰ ॥थ्वथ्ववांवनथ्वायाद्धावज्ञंसुवलवमयायांधायव॥ ॥सुगमयायथयंदः

[illegible]
[illegible]
[illegible] ४३
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible] ४४
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

वाथ्ठडयायया युत्तावन ननवांश्यु सिद्धिज्ञवा स्वनानयदसूनाधवां ॥ ॥श्वयावावांथ्यं नमः
नूश्वन यंद्वाया वानद्धिन यूदवांस स्विनंनयदयूमलाधवां ॥ ॥मूगमक्ष माशाक्ष याज्ञासि
वाद्द्वूवा॥सत्यश्यूनिवश्वनं त्रायत्नमांसल्हवं ॥ ॥ववाभजंवूवा ववथ्यदावबसाणाया ः ४७
वथ्यव॥ज्ञामित्र श्वयाशद्धविन वज्ञायाद्धनमथ्यनधवां ॥ ॥यगद॥आयजमित्रंज्ञानि
यायूत्तश्रूवंश्वनश्रुविं॥ज्ञाश्योंक्षी॥दयुविक्रसू यमानसूववाधवान्॥ ॥मित्रभयजवं

श्यायदासा यावसयंसंमममक्षुविशीलथायजावंयवश्वनादिमा मिवोजिक्ष क्षीथायजावंथः
वश्वनमावावववादविडसवाश्वववसायज्ञवंयवयवबदास्यंवज्ञायावाक्ष॥ ॥जंश्यवाम
मूद्धविनाक्षाविक्रयवज्ञ॥हथंवद्धवावदयक्षवं॥ ॥श्वलयूगनश्वयावजंवूवानयामवा
वंवावसायावविक्रवयवंज्ञावजंसाववियमावश्ववां॥ ॥त्रंववस्ताननिमिवानंवंया
गस्नवावमश्चकद्धावववासववक्षैंक्ष्युंज्ञसि॥मित्रनाथ्यथाक्षयंयथावलयावक्षयंनः

मयावर्त्तेश्वं॥ ॥जम्बुवनभव कामित्रहृषान्त मातङ्गयावग्नुविधिवनथनिवाद्गीय
नवलतलयंवाग्थश्रिदुवकमाग्ध्यन्नुमायामहृन कामिकज्ञयनवानमयावनमङ्गावांङ्गनय
याश्वंजनहृवौमययाश्वं॥ ॥अनकवंश्राबाहृमुयसमामनमवगाश्वान्विययमथविधंहृः ४३
ह्मायदन्॥ ॥श्वनलीमृगयामित्रसवृन्धिवायनमृगामवयावश्ववंयायागनवाहृवा
हृष्यद्भावश्वावं॥ ॥मस्यकिमकन्॥ ॥कामित्रमायुश्ववं॥ ॥मृत्यावृ मा ग्र

वश्रिपीनसङ्गमायश्यस्पहृलं॥ ॥मृगनश्वावंसङ्गदयपावववमहृगायाहृलंश्ववं॥ ॥
मथ्यावर्कं॥सङ्गदिहिवगावीमानांयगृध्यामिनकायिवं॥विययमांनिहिकावयानवर्मग्र
नष्वनथ॥ ॥यश्रिश्वावमाथवकाहृिनयायनङ्गावहृनियावनमहृहृन्नथ्यम्नथयवनः
श्रायदामावङ्गावभन्नयाज्ञानहृयावश्वय॥ ॥वावावृ मा॥ ॥ग्नुमयश्व॥ ॥काश्वः
नश्वावश्वंवज्ञावयश्ववं॥ ॥मृगवाश्वाकं॥ ॥माश्वाङ्गावितिश्रुश्वनेव॥ ॥मृगलश्वमञ्ज

तामासायाहंवानधर्वं॥ बावाशादवदवा॥मिवडकमर्वमया॥ ॥वाद्वनधाव
ध्वनमधाययावाधवं॥ ॥अयवाक्षनमर्का॥मिलेवविश्वसवावहं॥विश्वनादिहृगंसव्याः
कथंगुनववामयि॥ ॥मायवावयसीश्चवमावक्षंस्ववावेववा॥गश्चह्नयायकमोयः ४१
दाश्ववं॥ ॥यवन४॥मंतायिवानांमध्वस्वववाक्षिः॥मित्रायवावेश्ववमोशवानाम॥आष॥
वनाशद्वधवा॥कुत्वार्वं॥विमयिनामकृयिवग्रमाक्ष॥ ॥अयवकः॥डयध्वा॥लिंगिविष्णु॥

॥ध्रुवेममोयम्नमामववविंयायौ॥वंकुवनकयमलिनंवगवयिवसडधमर्थवदमि॥ ॥
डयवावयायस्थंसमर्वं॥वयवंवंलवंयायस्यावंश्चर्थियुत्रिडवनमं॥मालेमयायिवगवमिः
युखियौगश्चवृस्थंनवद्मवकर्वं॥ ॥मअश्ववाम्यिवि॥यंदूकेश्वनां॥ ॥यश्वनंदूकेन
यामक्षेमयश्चश्चव॥ ॥यास्वादवाश्वयमवि॥यायह॥मियूस्वमाश्चंवहेववंननूविवाविसः
नविविवं॥क्षिडनिवूस्वसहमावविश्वयधाक्षि॥सर्वस्वनयवलिमंसमावंवधामि॥ ॥

मश्रुथावसादृङ्गोध्वयाविवउवताबयाध्वयविनियावकृथंदृङ्गोसनयायुव॥दृयांगाविम
निष्ठयवध्वनलिजवध्रुवीवनध्रुयुवङ्गसयाकवासविविवगसदाविव॥ध्वनलिखिवसायावदृः
विसयिवद्धवयायुव॥ ॥नुध्वयगाववालमङ्कवयविश्वगुउदृङ्गध्वंव्रवगमानावयुवृ ४८
वलाकिवथवाध्वनावलाध्वावाकं॥ ॥थध्ववादववसध्वनलीथंनसादावध्वयृध्वलनथंग
वादावयागभूयांगाध्वाथ्वाङमक्षुडसाययावुववयदावकायनविस्वयावधाव॥ ॥मि

कन्नमाल्पानंसृमवहंदयविसृश्रयायादंगह्वंवायमिवदाङ्कसृत्ययवनवंगयवीथ्यसि॥
॥जोमिवसुगवु॥मिवाङ्कसंवामङ्कानवगडदवायडववमथ्वनंनयदद्वावविमङ्कनिश्वमं
॥ ॥नवश्कवयावेनादयोङ्ग्लनयननावनाविव॥नश्वविश्वाङ्गयावलाङ्काथा॥ओआम्त्व
यंमृव्वडमिसृयंवथ्वनाञ्मावयिलायागाव्हावविउंभयवम्नवतुव॥ ॥थवनलिथ्वंवृध्वलनः
ववाक्षोंडवदावञ्ञानङ्कयादंवङ्काकायावसावक्षायनयदार्थोमिवाङ्कयाववादमृगक्षदावया

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

४२

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

पुत्रपुत्रकन्यायिमनानायामितिकिंयाँ।नदिवायथ्वथुंण्डगावावास्वरू।ओरूपा॥ ॥ः
गथ्वश्वावना।माश्वमत्युत्रुवयायाचत्रयाश्वतंमहिथ्विविश्रीयामवंनमद्भुवग्रुवथाथंश्वावनामाय
वनामद्रुयालंस्वमामीनघा।वनामहिवथ्वं॥ ॥हिवग्यवायरू।।वयनद्वंवयवनामरूः ३०
श्वरूमवश्वयिनवाकेथ्वं॥ ॥दिवग्युवनवावश्रुयवानवागुवनंश्वरूयायमववथ्वंः
॥ ॥कथ्वायुकं।माज्ञीवामदियामस्वश्वा।कश्वायुत्रुमरूथा।विग्यामायकवश्वाम।विश्वः

मरूत्रुनाहिवश्व॥ ॥थ्ववाथ्वंनीमिमञ्जायाडदा।कविवमयवरूमिवचायवचायुत्रुः
ववश्वकवविश्वामवा।थंत्रमश्वा।विश्वामयाकमाहिवमश्रुव॥ ॥गभ्रु।यश्वकवानमाव।
॥ ॥विग्यमनश्रुकयनिमाणकु।यश्वथवा॥ ॥डका।कुवणकु।थांनदिमंदश्वाश्विः
श्वनायिमश्विना।मकश्वमयिया।गीयंममयथ्वयायवा।क्ष॥ ॥गकु।वमाश्वियायवाम
वनमाश्वियावनवमश्वंममवविविथ्वंयाकु।नमायवाश्ववावावंश्वकवमश्वंश्रुयिग्निश्वाछंमाश्वः

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

जनस्तुकनवायदवद्दक्कदश्वासमसश्चयथ॥ ॥वोषवमानयघ्नावथ्वंयावनंद्वडेगवव
वदावद्वाग्वमजिवमजनयुधिवजनववानम्वंमवछौववनयघ्नावथ्वंवमनकयंद्वा ग २
निव॥ ॥उववामव्वलालानिनिम्मिमायुगयम्लि॥वयालालाश्वमस्याक्षांमंयावंदगेना:
त्सुमां॥ ॥श्रयवंवमनु॥ल्लावागवांमङ्कवमिस्थमा॥क्ष्मदयमाधुजनानांगुणानाया
क्तिविजियांरंयायिद्धिमृष्माघ्नांमनूवध्वक्तिवक्कव॥ ॥अयथ्वा॥गुग्गुमावितंलाथी:

वांक्षांच्चेमामालश्वात्स्वहूथ्यवा॥वाक्तिग्नंवानवक्तिश्चमययमवमयावथा॥ ॥वनमेगुलाव:
य्यथश्वामयाच्चथ्याथय्य॥ ॥लयुयवजवानधावथ्वनयुगलमश्वञ्जनवमांमकु:
लायथवां॥ ॥दिवश्ववावद्विनिम्नस्याह॥ ॥द्विवश्ववयावदयिदावयावश्वाव:
॥ ॥क्ष्माश्वायिमाह्वेहयवानानवाश्वायुवन॥ ॥डआयायमानवावस्मायुवयन:
अनुवथवां॥ ॥वक्षावाक्लं॥यमाळेन्नवमाश्मिवजलेस्नानमञ्जावनिनशीयग्तुविलय:

नमस्तथयति युक्तस्मसथ्यो स्थितेशा। योग्येसजैन तावितंस्रतवसमयीत्यायथावतमस्वयंस्का स्या।
वयूवस्त्रवंसास्त्रभिनांमाक्षस्थिमस्त्रायवं॥ ॥स्त्रस्य॥वक्ष्यतमयायास्त्राव नेष्टृत्यांवलाय
कता॥वाख्यानिःसत्वनायुक्तमतलिमित्रस्य सुदुस्वनं॥ ॥शुद्धस्त्रवं यिथतःस्य नियुवदवः ७२
नक्षायपक्षलविकत्वयक्षा॥थिक्षयनिमत्वनायुक्तथलमित्रयायास्य॥ ॥मित्रयायस्तव
ध्वनया॥ ॥स्त्रस्थनवपनंतमसा॥विमयिदृश्यनंत्वयिनवस्त्रम॥ ॥स्थमदृश्यनक्षेव

वनधवयंध्वनयसूमाठ धववयंसथमवांव॥ ॥यथतथायदृलंसथवादिलंवस्थयामन
नयाम॥शुक्तस्वनवायत्यंयस्वतशावनयाव॥ ॥नस्त्रवंवक्षिमाहास्वडयल्स
स्त्रस्लवाल्मनस्थयुवकतंतस्यस्थावालीसाथ्यायकनववमसः॥नक्षवस्नुसववाइजिमवं॥
॥थवननंस्त्रस्त्रमित्रथवं॥ ॥ननतस्थ्रसकिनयाःयवस्थवंसस्यामकवत्॥
नमाद्विसयास्त्रा॥साक्षनविसथयेत्रायस॥संसास्त्रविवलंस्वविस्वःसा॥यायमास्त्रविस्थनंनमव॥

॥ श्वध्वा॥ ननथ्वयनिमित्रक्त्यावहिंश्वथ्वनवयूयननवाश्रुनश्वाविनन्सन्नायाय्याद॥

वथ्वक्ष्वाव्वंदूवारनघूयननवाथ्वथ्वथ्वंवन॥ ॥ननथ्वथ्वाध्यग्न्वदमय्यायात्वावनननः ७४

क्ष्ममनयश्लेश्वबिषंनायायेश्रुयावाङ्गिविवल्डैवा॥ ॥थ्वनविथ्वयनिनन्क्षाक्षिथ्वंसुग्याय्यनथ्वः

थ्वसुनश्वादिनयिविथिविबियाढनक्षागनसवावयाढविश्रामश्वनानवोथ्वक्त्यायावसादावासंश्व

ढनयान॥ ॥नवावायाय्यकाक्षिवथ्ययवामाहः॥वयय्यवाश्वनय्यादावमिंश्ववनं॥ ॥

श्रुन्याय्यनवसन्नाक्षावनश्वावावयूयननवाननक्षिवथ्यवानायमित्रथ्वश्वायमश्रुननावथ्वः

श्वाथ्ववं॥ ॥वदवय्यविवयकाश्वनाक्षिनंवसुमिथ्वमि॥ ॥थ्वथ्वयश्वानवंभनवदनः

नावयाथ्ववं॥ ॥क्षिवश्वावाकुनमित्रश्वागङ्कयं॥ ॥नामित्रक्षिवश्ववानश्वाया

यनवनथ्ववं॥ ॥वाश्वावाक्षं॥ ॥मिथ्वंथ्यवानयादनवववय्यवानबुद्धिमानूश्वनागमीक्ष

यवस्थनंयूथ्विमायवनंथ्यकजनु॥ ॥वायमावदमि॥ ॥श्रुक्षिमित्रथ्यनंसमिवुथ्विन॥

तथ्यपरनवंश्चव।ग्रुष्ठितंथायम स्वर्यंकयादवस्थधर्वं॥ ।।द्दिवद्धवावदति॥
किमवक्नु॥ ।।द्दिवश्चवनधाव यथ्विंगुथ्थयथवं॥ ।।वायशावयंवदति॥ ।।
धीश्वनयाव॥ ।।अस्थि वधुवावर्षो कयुवर्षो।वाथ्यंसवव्कग्रवितवावायड्डिमथ॥ २२
यियसद्देत्वमस्ववाक्षिथन४कुम्बिस्मक्कृथ्वामिका४।।यतियसदति॥ ।।थ्यस्थिवंद:
नुवावधुरुमिसवथ्यैवर्षो।वध्वयानामयुक्ववनीदव।।थयुक्ववनीमक्जवावावयामि
वजुतियियसद्दद्दमस्दुवध्वयानामकायववमवयंवाठकुतिमक्जथाम्पैव॥ ।।
यव४यवायदगथाविर्युंमर्वेयांमवावंकुलं।।यभिस्वयमनुथ्यनंवाय्यविदुमद्दात्मन४॥
वावमत्यादावविशेषम्भांसद्वेवयिथ्यति॥ ।।स्वनमसावयावेवांगवीवव्हैमानया
यूथवं॥ ।।द्दिवथ्यवीद्धवदक।।कवाजयाजावस्थयविंकालेथ्यं॥ ।।द्दिवथ्थ:
वनध्वव्युमथ्यज्ञवदावस्नुमदयवंजुजक्षधनवावादावय्युयथवं॥ ।।यवक्षायस्म:

स्त्रुगुनगम्भानं नमितानिवनाष्टवानवविद्याबामक्षत्रिहिं स्दगंयविवज्ञीयन्तु॥ वयाः
मार्थं क्षवमाखृवदगमंश्रृज्ञवन्त्राबयाद्धथममाथ्ययावंमदनदाव मित्रवष्टवंमदनदाव २७६
विद्यागमन्त्रमवंमदनद्ववथर्थिंगृश्मायथर्थिंगृदगमावनमाखवं॥ ॥नुयवक्तुवाथः
क्ष्यथनविद्यन्धनत्रयाक्तुनमाद्धिमं॥ ध्वनिनत्रत्रियावाजानदीविघन्क्तुयक्ष्मम४॥ ॥
ध्वदनामहृथायमवमवयमवाव ध्वनिहृतिवाज्ञा स्ववेघथवंथवं॥ ॥ममामामः

यिमत्रनय॥ ॥खवनजन्मभाथायमखाद्यद्भयवं॥ ॥द्वधवायमक्तुनमित्रमवा
द विवित्रवथलायमन्यमवमवज्ञयंजमम४॥ ॥धनवीज्ञयथ्वहिवथ्ववमित्रुधः
वाद्दिननानाविवित्रवथ्ज्ञायावमन्त्रववादायुसूत्रीयामनियवत्रा॥ ॥यवामन्त्रवाः
दूवादवनाथ्वलयुयनववायावुद्धयाक्तिर्थंमनावेवनाव॥ ॥यम्ववलयुयननव
वायिननमन्त्रवद्यमवबनयदद्ववमवनानावक्माथ्याजिथ्वयावं॥ ॥यम४॥वावाथाः

दिवाछुना स्वांवा गुह्मागवं॥ कय्यवज्ञा विश्वकन्यासवँस्यायायागवायुन्वसा॥ ॥ वस्यूनधा:
वस्या वालवाङ्ग्रसान्वं दृष्ठ्जरसान्वं यावमाज्ञवन्वंसे थववझुववदाव युज्ञायाय्वमावय्ववंसम
स्वयांसुत्यागवयुवुज्ञदवस्वेग॥ ॥ वाय्यसावदंकि॥ ॥ वयूयननवानधाव॥ ॥ ७०
वयय्यसाविय्ययम व्रस्रीयुज्ञा विश्वदि॥ श्रमायंयुथ्ववमोषंयुवीमवावुश्रववावकवादिव:
श्यवानाममूल्यवाज्ञा॥ ॥ रामित्रसन्दुवज्ञ्यासिन्वंथ्वसयुज्ञामानयाङ्कनथ्वसह्नयुयाथिं

थ्वत्ररसामेंदायुथ्याम्लासमस्वयुथ्ययाडवाडमवय्वडनदयावन्हवायुथ्यवलाववोदिवथ्यव
नामङ्कुयावाज्ञायथ्ववं॥ ॥ तवस्यागुणसु ज्ञिकासल्नश्रह्लिमयलनमास्युवज्ञायदिकाऊंस:
मथ्वेश्रस्यादियह्नाविक्रावश्याम्लाननुयवह्लिमवानु॥ ॥ थ्वस्यागुणय ज्ञायमीनदावस
दावथ्वावनागवाज्ञास्यंनंसह्ववथ्ववंथयथ्वायायान्नुवयूयतानवानमवस्हवविवग्रीवयायागदि
वथ्ववानहूदास्ववंवानव॥ ॥ वनामल्हवस्यादवसंयुआह॥ ॥ थ्वनंलीथ्वसन्दुवत्र

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible] ।। विना कष्टेन वा ।।
[illegible] ४ ।। विना कष्टेन [illegible]
[illegible] ।। [illegible] कष्टेन वा ।। [illegible]
[illegible] ।। [illegible]
[illegible]

[illegible] ।। विना कष्टेन [illegible] ४
[illegible] ।। [illegible]
[illegible] विना कष्टेन [illegible]
[illegible] ।। [illegible]
[illegible] ।। [illegible]

नमदलत्याय्यह्मवमानस्याथयुत्तमिचमंकसावायुयानवश्चयुकावगवंसह्मसावानिह्मयन:
युसमिज्ञाल्हिंगनायाय श्वस्वद्रुडमवयनद्भववर्दा॥श्वगाथंश्ववं॥ ॥वुताकच्छैयुद्गनि॥
वथमवकु॥ ॥वुजावह्लुनदनयुमायगथश्ववंव॥ ॥विनावह्लैवश्वयावि॥ ॥विनाः ५०
वह्लुनवन॥ ॥यास्किय्येवविमयवयीमास्मीनामनमयी॥ ॥श्वविनवोवडमिसावाम
वीनामनगवस॥ ॥नस्यावंद्धनवायनानमवनिवसदाश्वनावमवि॥ ॥थनगमवः

स्वनवारनामवाहिमदाश्वनीवसवयंवाद्र॥ ॥वनवयसिमवयसिवहेमानावामावस्थि
नस्वनसाधनवय्योक्षीनावमीनामवनिवयुत्रीययानीवाव॥ ॥थ्ववानिनस्याथवसनवं
वामसवनवदावश्वनयावबननिनावकिनामवनियास्क्षावकाव॥ ॥यावसवववावी
क्षेयाह्मिजयवेजयन्नीवक्षोवनवनिवस्तुव॥ ॥थ्ववानियुत्रीजुकिसहवीवामदवयाह्री:
ववीवयवंत्रयोवनवनि॥ ॥सावयुद्ववावनस्याथसंवाख्यायनावहु॥ ॥थ्वस्या:

थयूसमिनस्वयासंभायमजवं॥ ॥यनक्ष्मसिनिवढिमाहेंलोनांयक्मोलानांबवाविव॥मः
भानवामनक्ष्मीनांजवायीत्याहियथमी॥ ॥यवाथ्वंधावबाविक्षानदीतवयंदूसिक्मयावद्रुः
वाथ्वेवायनवीतवयूदुसिक्मयामयवाथ्वंस्मीयायवमबदजवानयिकवयूक्माथयूसामियावा॥ ६१
॥यायवक्ष॥यावितक्ष्वयिहयूयूयूंमवाभामवाभिवा॥क्षेयघ्नामिवमथ्नयदथ्वंमत
मक्षीयव॥ ॥मवदृढ्वयवितव्यामविवाजूबामवानू॥यव॥यनामाजीविमामायवगुवीया॥

नरुवांमवा॥वृह्वयवनवूनीवाथ्वीयानथ्या॥यिवविवमी॥ ॥थ्वयाह्वंयूवामिनथ्वमिमाः
यूकिमवाढयूवाथ्वंधावमाधनदयवयामाथ्वायथ्वामायोनियाथ्ववंयामावुढयावनिर्भ॥
याममायानयासिक्वं॥ ॥यूथ्व॥मायमीजूमक्ष॥विवियायाजलिमथूस्मिनीदमथ्ववजि॥
क्षायालाविवावर॥ ॥यमाथ्वंधावमायृह्वयजीवनक्मीनयमजिवमादयंमवठनादाकस॥
नयालानयूढवामममनक्षावीह्यावबाढथ्वंगंयायवानं॥ ॥थ्वथमावित्नावबीयोवनदः

यादकिञान्नपुत्नमयशोसवनायिवतिञ्युत्रनशदानयामसत्व॥ ॥ध्वनतिर्थंध्वलिङ्गव:
मिनयोवनयासृत्कंमानथवद्रुवयामञ्जोवावावक्षं अस्तिनंवानियायुत्रयावयवनस्थोमनः ६५
॥ ॥यवठ॥स्वमञ्जोयित्मलाष्टिनमवमक्तियाबालवमसङ्गवियायुदवुवमानिधवान
यमायामाविदमवक्व॥मंमयमदयुवस्वनीयवमसहवानतायाःश्रयसुवायाद्ववामिथिः
कंथुवमनं॥सयुत्कठक्षीयाम॥ ॥श्रुयवक्ष॥यानंदुर्ज्ञनमंसमवेदयेयावविदाम

मां॥स्वन्नमयथयृत्कवामानावीनंद्रयनानियश्री॥ ॥विश्व॥स्यनंनाक्षिस्वानंनाक्षियायथिः
वानव॥मनननावदनावीनंसत्किनयय्जायव॥ ॥श्वायमदनमावीमवावसामवन
दावामदनमाथ्वसवानयवनमिमामाविज्ञयमश्चावधवंनावदंकवादास्नाव॥ ॥ः
सुष्ठञ॥पृनवनमामानावीवद्यामवमनायमान॥वमायुवनवक्षिश्ववेवास्यियययद्ध
॥ ॥यवययवक्षुल्यमिमाहंध्यावमिवकुथ्यमिजनश्चवनगथ्यमनथवदानयुथ्वंमिवः

मिसाव यकन्त्रवानदावत्रयुव ध्वकनत्वानि क्वनव यमनवधर्मं॥ ॥ऋयिय॥यिकावक्व

मिबोमात्न कदावक्वाबि यावनत॥ यूनाश्वध्याविर त्वव नक्वोयाकाधमयँदकानि॥ ॥दवाव:

वन्नवाव ववुनमियवयिदयावनम यूववनमिव्वयाधिव॥त्रिथिक्नवदावकायनमिव्वयाधिरु ६१

वक्योयाधूवनं यवक्नयमय॥ ॥स्ववादाशानीलावकिबलावलीकिवनवाद्धव॥यथिक

मबोनवनिखूजनविंगंकालायँक्ष्ममाविनाक ॥रुकूयायध्यवस॥ध्वनीलावाकनबंस

वगालाय वल्लमयमश्वामवालिय्कुजा ववनानावधान विलाससयादयाक्षमयन॥ ॥वव

मल्लक्रिमायास्यँयक्रियवलाकासकमालायवकसयपुदीक्वानिकलमालियँध्वसुवनबति॥

॥ध्वस्वनम यूमामिववव्वदाव मश्वनववदकाव नीलावकीन वसाकासाताय यसमयूदावधुय

नवँ॥ ॥जालष्ठवलायिक४॥ ॥ववववयँवत॥ ॥कदालिक्ष्वनमयलाक्वसामिय

द्वनिवीवक्कूधविन्नयक्रानावक्ष्मायुवविक्वामानिवनक्वयाकाहक्याकक्वावनंजाववविक्वायमा:

निलावर्तिदण्डिका॥ ॥श्वेतांशुमूर्तमिषसाधु नादेवयुगान यान्यदमावसामिषसवादहस्तउत्तीन
विक्रयवं॥ ॥नादस्मात्युवनिर्विवाशायायाष्ट्रक॥ ॥ध्वनतीक्राद्वनीन ध्वस्थयूर्तमीवंस
श्रीसावानवनायवयवांस्यायामयावध्वानिवावनिक्रूतउत्तीन दण्डवयवं॥ ॥ग्रहाहृदेवनीमि ५४
॥मूर्धवनवलायस्कस्कवानवलायिवालनमात्रकविवर्यांकनविविश्वावावनवंवायवाकृत्यादवनः
मवंवयिश्रवि॥ ॥विनावकृत्तिनश्रावा॥वं॥श्रीवज्ञनश्रयायाकृयाश्चानिवावश्चायकृपुवस्थाः

स्विनुंवानवनदयुयवं श्वश्ववायावत्वविमम कवादावविक्रवयाववानवमयुवामस्वायस्तुया
श्रुदिकाद्वयदवधवंधवं॥ ॥यवकं४ाध्वनवाह्नावावलवाह्नावासवंवासवायस्तुः
त्वंधनमूलंदिवाह्नासघ्युयवावयक॥ ॥कवं४ध्वनिंकमावायकनयविवाकृवानविवनंस्व
निलासममविवसविवं निश्चानंयुहिवं॥ ॥थध्वविनवयाव यनविवायावथविस्वनः
यावसयस्कयाववज्ञनवावावसवंयादवयाकृधनवावं॥ ॥ववं४युप्रहृद्यांहृनिवसाकें

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

वाक्यानिश्चनयवासचायसमकव॥ ॥गद्यवाकं॥अयक्रविसगदेवगुग्नेयक्रनवृत्तसन

स्विनादविद्रयवनावयथखवमायं॥ ॥अयक्रद्ववियुक्तवद्धावयुयनयलयादनि

स्वनक्रव॥ह्लानिवक्रवविरुद्धवबाव वनाक्रवयायवनथयासयवातंमद॥ ॥अयक्रव॥स

नसिमियसकासंवायेयंनरुगयसि॥अयिनिर्वाणमायाकिनामनायाकिमीकवां॥ ॥

यानिवक्रमवायेयावनसियेयवक्षयनक्षमयावगजवयंवादयांकनसर्वंअयिन्वादवः ५१

मजिवर्थयानिवक्रयनकमवाव॥ ॥कि३॥त्रुवासक्वकयवहुवसामनस्विनथ॥ः

सर्वलोकयवामूर्द्विविसक्षवनदथवा॥ ॥वानयायविथहानिवक्रयावनासः

वाअमासमक्यायिवसवयअसावनसदावनान्थंडयूव॥ ॥येयानिवांयुक्तीव

नंकदाकवयाहिवां॥ ॥भवयावयावव्यंस्माडवानअगिमहिंया॥ ॥यमाव:

नेंकैयीवक्षीननयाने३संकयिमाइनवथ॥नायकावयविवेयंह्रयनथयाषिवामवग॥ ॥

धनमाम ताव ममसंख्याद्दं यानमावक्वाकिंगु थ्वमवसानानं छायायाकाम दुरुयवा याथ्वाबमद्
यर्ब्वं दुःखियाद्दमवयाग याथ्वनायाद्दवानमानताव॥ ॥थ्वयवक्वं॥वाखिद्धिंयमाकिः
द्वीयविगमकुछयरुमवबाजमा॥निक्कजायाविरुयवयाविवानिर्वंध्वमायाविथ॥ ॥नि ४८
वंछुःमवमाविसाक्वाविद्दिमावुद्याममंयुखक्तिविदुद्धिःश्वयमस्याद्दानिध्वमवामाध्वीयस्वमाः
स्याद्दं॥ ॥विंश॥ववंवाथ्वमीनंवनमवनमुक्तं यदेद्दवं देनञ्जथ्वंवंमानवयवबर

वाक्विगमनंविवंयानस्थकानमविज्ञनवावाबाकिविकिर्वंकिश्वाविद्दंनयवबधनास्वाद्दः
नमस्वं॥ ॥मवनाक्तु॥मुक्तवक्लेयाद्दश्वानाकिंद्द ङसयज्ञास्थंक्वनाविगनमवंयाक्तयंः
किंग्वमवयाक्लिमवमयमाकिंग्व यानमावक्वाकिंग्व मवयायमवयानानथ्वमाथ्वनमाकिंग्वकि
काछ्वानकिंग्वयवधनवाथ्वंमानमाकिंद॥ ॥थ्वाक्वि॥थ्वयथ्वमानमयिनञ्जास्वबमाः
जलवनावध्वंद्दविंजनवाथ्वयद्भुविकंयुजमावनथ्वाथ्विवाद्दवमि॥ ॥विद्दथ्वमाछ्वम

हंयथीसनल्यातंयाजुयास॥ क्षनश्चावथिस्थिरीयथुन्हूलवांयों॥ ॥स्वनथाय्नेंथपुदि
याश्रुद्धंकयथोउ कुमथ्वनं॥ वाजुनंथ थवाथिनं थिग्यंभ्वं आदितथ्वना३॥ ॥भेवथाकंद
याव सथनथकाल थ्वहिं कस्तूल संथ्वनस्थाङ्लनउ मिथुनदय भवननयाल [illegible] नयथवथ्यथानय
नुस्थयाविथथ्वना॥ ॥स्यथ्वं॥ यामी विनथ्वथाभिथ वान [illegible] जियवावरायथ्माय्यं॥ जुवांनकी
तनावनंसाम्यविग्रायाथ४॥ ॥समथाथांवायनवाव मवयाथनर्थ्यंना‍ह भवयावसायव॥ ८७

नमाव ध्वन्नु थामार्थंमिकसिमङावथि श्लामभाय॥ ॥इथ्यावयथवालावथयिथ्वनंगुदी:
गुंयेनलनावर्व॥ ॥कथ्याथाकं॥ ल्माकन्यूथिथ्वथनि॥ लावाजुमथ्वकेल्याल्यालाभाव:
माल्लाति यवकुवंदेमानवा॥ ॥वमा दृढोविनावल्लु रुजुङ्कावनंभ्या [illegible] नदुनमादिव
अुश्वादमाविङ्ङयन्॥ नवाथ्य मासन्तुम्लाथियमानमथा॥ ॥कथ्यथाकं॥ सञ्चामथ्यल:
युलल्थाउत्सुंयथ्यथमानसीडयानंगुउयाथ्यानतूव म्लाद्दलेवलुथ४॥ ॥जुथ्यथ्वा॥ सं:

सायाम्रुकरस्कानां यस्मस्वंसक्कियकसां ॥ ककस्क स्वननलस्वानां मित्रस्वमस्वधावसां ॥ ॥
विंस्व ॥ वना धियंगु वंनानवनसन्वेमनयुस्विवं । यना साउ सुस्कनक्कस्वा नैलाश्वमवलन्विवं ॥
॥ स्वायिय ॥ अगमाविलग्धवहावं महस्वविदवग्रथं । अनुकाज्ञीवववंथस्वकस्यायिद्विवि १०
वं ॥ ॥ यम ॥ नयाजनससंदुयंवासमानस्यरस्नुया ॥ सस्नुस्वस्ववबयासस्याश्वेक ः
यविनावयं ॥ ॥ ववाक्षस्विस्वयस्य विनवाग्येयविस्कद्ग्रीयानश ॥ ॥डकंस्व ॥

वाश्वमीनुनदया विंसास्वमवागी ॥ विजनाउ ॥ वाक्षनदस्वाज्ञाववउविं याघ्रुयंयविस्नुद४ ॥
॥ नश्वाद्दि ॥ स्वजदवाज्ञालस्या थिकुवंहाजनु ॥ यासंज्ञनयदस्याथे अन्मा श्चिस्वथिवीयद
जनु ॥ ॥ अयवस्वावानियवानिवायासंस्वाद्वनस्वारयालय ॥ विवायीस्वयुयस्वायंमि ः
नस्नुयंयवानिस्वमिय ॥ ॥ हुस्याबाद्याहंविक्षनवनांमायन्नु ॥ ॥ क्किवग्रवनथाव
धस्वाविक्रयायवज्ञानिजनवनाक्कवसावयाश्ववां ॥ ॥ अमाहस्मायुश्वादयादननमिवना ः

याँ थ्वनक्व व गुङ्ढि व ग्वक्क ॥ नव याव नि मिल नक्वा वु व ब्व गा व य थ्व ज्ञ ॥ श्री गद्भ ४ व या थ व थ्वकं ॥

॥ थ्यु य व क्व ॥ दनाय क्वा गम्रु व न ख्व न न ख्वा नि न्ना य दि ॥ ज्ञ या मः ४ कि न्व लं व थ्व न न थ्वः

नि न्ना व यँ ॥ ॥ वा न मया व क्क थ्व म गु क व थ्वा डाया थ्व न न ञ्च या य थ्व क्क या थ्व न या नि ९२

४ ॥ य ञ्जा ज्ञ न थ्व थ्व द न वं ज्ञ न्वा ॥ नि थ्व न थ्वा नि ख्व य वा थ्व नि या य य या ज्ञ न ज्ञ ॥ वँ न्व न न्ना व या य ॥

॥ थ्य मं न्वा या न न्ना मा थ्वँ न्वा य न स्य थ्व नं य थे क्व गु स्यं य मि मि कि म थ्व थ्वा द न्वा द्भ ४ थ्व न गा थ्य त ॥

॥ न द्भु कं ॥ दा नँ थ्वी य थ्वा क्क दि वँ ह्ला न न्वा व कि क्क मा ब्वि न्वा ॥ श्री थ्वी थ्वा या म दि वँ य वि लँ द्भुः

ज्ञ न्वा म न थ्व कु थें यँ व ॥ ॥ थ्वी ॥ न व व न न न सँ थ्वु का न व न या व ज्ञ दे न्वा व म द य वँ ह्ला नि क्क ः

मा थ्व क्क या ठ न्व व थ्या थ्वी या ठ थ्व न थ्व व थ्व य थ्व न्वा न सँ यु का य व यु य द्भ न्वं न ॥ ॥ ठ कः क्क न्वा ॥ वा लँ

थ्वु न्वं व या नि थ्वँ वा लं थ्वा ना स्कि म क्कु य व ॥ य थ्व न्वा क्कु य ॥ न न थ्व न थ्वा ल्मा नि या वि न्वा ॥ ॥

गथ्य थ्व न न्वा ॥ न वा न्वा वँ न्व क्कु य थ्वा य मा व थ्वु वि सँ व य द्भ थ्वा म न व ॥ थ्वु कि सँ व य या थ्वा न नि

यद्वनमूयावश्वयानमाक्षदवय॥ ॥साद्वीतु॥ ॥दिवश्वकनश्वव॥ ॥
वथमनतु॥ ॥अमाद्ववाथ्यवं॥ • ॥मद्रवनाद्द॥ ॥मद्रवनवन॥ • ॥अस्थिव
स्यानवाडकवास्कश्याशैववनामयाश्व॥ ॥यृष्टिशैववसवात्यानकाडवसत्यावबंथा: नंउं
क्षरैववश्वयानाक्षमवव॥ ॥सवैकदायायाह्विवृद्वसविश्वमवीमथ्यैमनश॥ ॥
थ्वनवन्तुयायवमलक्ष्वनविश्वामवीवनवन॥ ॥ववस्कनश्वांश्योदिवभूतमामाम्या:

वासूमाद्यावाह्नाक्षिकृशूवश्वाहम्यृश॥ ॥थ्वमववनहुवसुक्षवादावजामवववनवधि:
कवाम्नसृक्ष्यवनं॥ ॥ववस्कनमृवतुभानिश्चायगुवावक्ष्मवनाह्मश॥ ॥यथ्य
क्षाश्वदावसैश्वववनववावसंनयावक्षावववनक्ष्माव॥ ॥शुकवानांश्यागवृयवनया:
ववाजिकृवीननमथ्याक्षेमृयैवादक्षकत॥ ॥क्षावश्वववानवाद्यावतवगद्दनक्यं
ववननलावावश्वमववयामं॥ ॥मत्रघ्निनङुमवयाम॥ ॥यथ्वक्ष्वानवाहा:

वृतव त्सिमादवर्थद्देन॥ ॥पयतः॥ जलमोग्निविषंगस्तु क्रुद्धाधिः पन्नगविषवानिमिः
वंविवसा यवक्रियाधाविभूयत॥ ॥यथ्यवसूसालंस्मसग्निमसविषवङस्कनकृवाः
वयद्वेवनग्राधिनवीत्रयवाङ्क वाविद्याव दवयाग्गवोनवयुवव॥ ॥नमुखाक्कव द्विधः ७४
यावतामकंस्मुवतः पविक्रमनाहावाथिना नूमयाथाषयुवयानवल्लावयामास॥ ॥ष्वन
लिथ्वंवेचवावनामकंवृवानक्ष्मवर्यं शालयमावक्कवसुवा याधास्मा थमिसिद्दवाद्दस्वनः

व॥ ॥याबाक्कविक्रयामासयक्कायंमनमूयस्तुवं॥ ॥चयस्वावक्रंस्पुवानविक्रय
यवंमहासामज्ञमंत्राकक्कयध्वं॥ ॥सुथ्वा॥ अविक्रिमानिदूःखानिमेचवायाक्कि
क्किना॥ सखाश्चयितथमात्रंदेयमवागारियुवा॥ ॥दुःखमस्वयमययाथमदूम
विक्कवयायुविवाय्यमथ्याथमंदक्कसजायवयूसवंममिक्रवयाथ्वंजायवयविवदंयनकृया
थ्याथवं॥ ॥रुवत्ववांमाक्क्षेमायमवंजावक्कोवनमरुवीयाक्कि॥ ॥ष्वयावात

वस्थियर्थं ग्रनवयावाथवं॥ ॥ववदयथसनुकुश्वायां॥ स्वगुरुद्भिनमासायवथं स्वाव्दः

यासिंहुं स्तुस्नावथ्थववासि॥ ॥न्सावद्भयांयलावथ्विसियूप्सपद्धिडंवयागसानिनयः

धर्वंश्वमायावग्ग्यङ्कवा॥ ॥लनन्धिश्वमायुवश्चङ्ग नवववकुयाकिभनवनुयाङ्कविनिरि

नश्चयवनवनंश्वग॥ ॥थ्वनरि निस्युश्वमाद्धिडवयाग्वङ्गयाव निस्तुनश्वनावयाय नुवुङ

नस्वयावायवनत्तश्चवसिंव॥ ॥ [illegible] ॥ [illegible] ॥ ॥

मनुवसाद्धिवश्वदानथ्वननत्रिसिंययमनवश्ववंत्रनश्वया॥ ॥विङ्क॥यद्दवसियः

स्वश्चाविनद्दवश्वनिनाथ्वन॥ [illegible] ॥ ॥मश्वथ्वमावः

नयुश्वयाश्वाथमनश्चश्वनियाश्वनश्वायश्वनयवश्वश्वश्वमसिनदावश्वनश्वनभमवङ्कनयुय॥

॥ङ्कनिंयाउविमनरीमायालङ्कन॥ ॥ [illegible] ॥

विङ्ग॥ [illegible] ॥ ॥ [illegible]

म्प्साधनमयावृ आयमसयस्वदवयं द्वाम्रियादमसदथम्क्षमनुस्थयाग्रुतक्षया॥ वव
न्स्वस्यत्नान्द्दन वत्नयाव विमर्षा॥ ॥ थवतनमाचितक्षु नदस्यान्तयाद्धनथवयावश्चितः
वा॥ ॥ यवठाथास्कण्थ्रविवानिमयक्ति मुस्यायस्वक्रियावायुयुयंसविद्वानु॥ सस्क्रियमथ्या॥ ने६
ययमानुवाम्हां ननामममाकत्मकशाविधागं॥ ॥ स्मृयव॥ नस्वदत्यमयाश्वकमायकोवा४ः
वावामिविशनविधिविगुनोवि॥ ॥ स्वग्रयाविठंस्वनलास्थि मायियवागयस्यस्थमिदयुदीयथ॥

४॥ ॥ मदवक्रदगावित्यमयीमिरवावघीस्या॥ नववयितनमभंकवंवास्यनगस्थानमाकन्क
दस्वाकक्षनस्थानयाउ॥ ॥ क्षितिविशायमविमानुस्वस्यनंनयविषयक्षनु॥ ॥ थवयनलनवः
स्मुक्त्रयवायक्रूशामाक्रयंवासयुसिमनथ्यंथनकसयंमविमास्थ्वितिनथ्वकस्थ्यनयावमः
नव॥ ॥ ववायुयुयवयनसमक्रनु॥ ॥ थनवायुयुययावयन॥ ॥ दगानत्
स्क्रमाद्धक्तिसिदामत्युक्षामाजावनजावनिम्वसंयाक्रिवावाठवायुयुयाभुम॥ ॥ दगमा॥

दर्कं वायियावानवनिव सिंहमत्यु वूय किसि मवनयावावासा स्यं ड थ्याय मंमायु व क्वाय स्वावूयु य
मूय॥ ॥कथ्यवाकं॥ क्वाविवयमनस्मिना सावियय क्वावाविदघ्वशाङ्गेरूपा॥ यदगंग्र:
यमनूवयवरू वूय वाह्नयवायाङ्जिन॥ ॥यदय्यानयलाङ्कलयकवगश्शिदावलंमाकवव बे बे
स्म न्नय दकवाह्निय न्हयूधिविक्व म्वायूय्यावनश॥ ॥नियानमिवमण्डवाक्ष्मायश्यूवि
मिवाह्जाश्मायावागवमायाह्निविवमाश्मवसंवयश॥ ॥विश्वश॥ सय्वमावकिवेल

श्वाहूश्यवायविर्वनंयथ्यान्वकवयानि वहेल न्ह स्वानिवसम्यानिव॥ ॥मयूयविवहश्व
दूश्वयालिवमाय्य ववाहयथ्रमनूया याश्यश्मास्वहविवा॥ ॥ग्रयववश॥ ह्माहदवाय:
न्नमादियसवंखायाविधिहंस्वमनमसार्कं॥ धुवंकाकाहंसमाहदेश लक्ष्मीश्वयंयाग्यनिवा
सहवा॥ ॥हमादनमय्यूकाश्वदियमवविधानथ॥ ॥क्रियासवववयाश्व:
श्ववानसामूमविक्वाग्रवयाश्वावसावहस्माहदयश्ववनसम्यनश्मयावलांक्ष्मीश्वंयमथ्यमव:

सर्वार्थसाधकाय॥ ६॥ विघ्नयष्ट॥ विनायकस्य धीवरस्य गङ्कि वन्दमानान्नकियर्द्दंशविस्फारयि

पुरुषेणयविरूपस्यन्दयाक्लिष्टयन॥ नरूपस्य सुरूपाणां ६ नरामुनयावाक्लि विद्युत्पुत्रिभो हि घ्नाः

बलबामान्नायिनस्यन॥ ७॥ किस्क॥ यनयानिकिं हिमरुक्ष किंवानविकयाविघाटनयया ः

सिद्धवनानि दिव्यं वकसमायाधायामामनुष्याना॥ ८॥ यक्षा॥ सुरूपायास्मबुद्धीभिनवगः

स्यानि स्याविक ४॥ विस्फलोवायस्न यक्षानिघ्नावनानि धनानिव॥ ९॥ नंस्यसवाहवायायाबुद्धीः ८

गवयोषि नवायवस्थप्रस्थुस्थाविनय्यायक्षीयावियाडयक्षागध्वनयनाबमया याबनधनः

ध्वमार्थं॥ १०॥ नयस्थ॥ सुस्थर्थनाविवयुत सावियक्षगनिर्म्मिता॥ यनोविद्यविभज्ञः

क्षोभा ६४प्रुस्वबनस्फला॥ ११॥ यक्षयानिमिकनमविवनमयास्वकसनवस्थंविध्वत्रा

स्यानिमोक्षयाढ ढस्यूवगुभाथांस्यक्षामनयवाक्षि कानजयहनंमामयाकुरुमानवयाढः

कुरुद्धानवा थं॥ सायक्षमित्रा॥ १२॥ यनगुह्यिं हद्दशनाहंसागुवाध्वहविबोक्षवा ४॥ मः

यूथाप्रिजिनायनसमस्तुह्लिःविभ्रस्यानि॥ ॥यवन्धयवमश्ववनंदंमत्रायुवन्धुयानकः
युयादुवन्धुयात्रभ्यासमानाविविवनानावन्धुयात्वन्धयवमश्ववनन्धुवन्धुनीविपुवध्वत॥
॥ज्ञ्ययवञ्च॥समांढवयांगुगुप्तामित्र॥ ॥ज्ञामित्रादिवथ्वकागुकयवकानदञ्जन॥ १७
॥ज्ञनयकवानद्रूःयवायायपञ्चिवियाह्लिस्र॥मादयपञ्चिवमंयञ्चावाथ्वमथ्वेःसयावन
४॥ ॥दुःपलवत्नसाश्रवितिदुःयपिञ्चवयांवियाक्मसाश्रवितिसंनाययादमयपितिसमादयाः

ःसनदावसयवभ्याश्राविताभ्रावथ्यंमदा॥ ॥थवम्याथेयस्याविह्लदावसभस्यानिवादः
मा॥यम्रानलाञ्चिसयादुवासयशःनेवत्र॥ ॥यथभ्यामित्यादाजम्पयञ्चिञ्चिःध्वायस
ःद्गुविभ्राकञ्चिनगवीनमयाम्नाथ्वामपञ्चपाविहृत्वान्॥ ॥वाज्ञत्रःशलीलाद्यन्ज्ञावकः
स्वज्ञनादयिनयमथ्ववानिर्यांगृत्याःयामदनाःम्रदाः॥ ॥जस्मानिज्ञाधयादल्यविंः
नद्रःम्रमसःयवंङ्गःम्रासंयवयमानाञ्चिःयञ्चम्रननिवह्लेव॥ ॥सथावसध्वायथदुःज्ञः

ग्दुःखच्छेत्तुनं सद्धर्मसंङ्घस्य त्रायाश्रयं विमसिद्धुसुसा विकायमजिवा ॥ ॥ ध्वनं काव्यसर
र्ग्रं वस्त्रवस्त नयायमा । तस्त्रना श्रायत्रसृहत्यध्वनत ध्वनविभर्व स्कस्मादवान्तविन्द्वयसु ॥ ॥
ध्वनमदवाव दयवावाथिन दवनावयन्धनयवयौन दसां त्वाद्भाववावमूलयायायध्वं थवन ८०
ध्वनविन्धनयमवय ॥ ॥ हस्त्वयविथवायवायव्विद्वःवा क्कुर्ग्लं लःवयास्तुग्रगवाः
याउयायःगिवसिद्धिना ॥ ॥ य्ययवद्विवांय्यनम्भावांयुनिवर्ऌना । व्यायकृतवाथेन

साश्चैयवावायुनिवर्ऌना ॥ ॥ विम्बकृता ॥ मम यकृत्या मानय्वैद्वसद्धवावालीयवां ॥ ॥
यनश्वाश्च मसानान्का स्यघयाःश्वाया स्मल्कृत जरह्मनाथयविल्यागाश्विनिसम्भानकुवस्यमर्लना ॥
॥ वय्ययगनवाद्रुना ॥ ॥ वयूयकतनव्यव ॥ ॥ वश्यामिमद्भवसावाथस्युद्दतियरु
गुल्मस्तसि ॥ ॥ ध्वय्यमङ्गुन निम्नाकिगुनवसय्यनजुवधवां ॥ ॥ यनःश्वासमवव
वांनि खंसायसुद्धवमगवमश्वागजानांयक्षजग्मानां गजानवयसूयंश्चवा ॥ ॥ छात्रय ॥ सनवाउः

विमानवानां मडेठिमसत्यवयवत्या॥ यस्याथिनावागवनागवावानाश्चविदक्षाविमख्यवयाक
न्ति॥ ॥ गदवक्तमन्थ्वयाद्वावंक्रावीदावगा श्यवंवद्कन्ति॥ ॥ श्वयवावमदिवय्यव
श्वाधवयाव थयनिस्वक्षंस्वयूदावविदावमागस्यनवान॥ ॥ अथविक्राङ्गाक्षामयुगठवाना: ८१
यिक्रासिमानयागन्धमिरिवा॥ ॥ थनतिथ्यविक्राङ्गनामस्यवासाक्षिनंथ्याउवथयनि:
श्वाठथयसानायवानवया॥ ॥ कमःयश्वासयक्रयवहुमालवमन्थ्वाजवंथविय॥

॥ श्वथश्रयमदावयनववयदावमंश्वलंश्वसाङ्कवल॥ ॥ गस्थवाविववंयविय
४॥ ॥ दिवश्रवाथावमंदूदाव॥ ॥ कुङ्गीयवावावयुक्तायंगत४॥ ॥ वावायव
याव सिमाथावंक्रवन॥ ॥ कमालयूयमनवानयदठनवायालाविकथयश्चवद्व:
नायागयययनथमद्भीमिलिश्यायविक्षाठ॥ ॥ थनलिलयूयवनवानदययाद्वुसनंव:
ववदूश्वयावलिथ्वश्वयाववनन समस्कंवयावदंश्वंवमनं॥ ॥ मङ्गवणकं॥ मित

८२

मियमा मि माषाश्चयानं॥ ॥ सर्वमन्त्रावर्त्तक॥ ॥ स्थिन मन्त्रवयश्चाय॥ ~७॥
मश्च मुद्रावज्रनयासिमा हुसिविनिर्क्ष नवनग्राधासकृवनि॥ ॥ वज्रामित्रमुखमसनानं
मुद्राधनिर्जनवनमगाथ्मावसवधर्वं॥ ॥ मुद्राणाकं॥ ॥ मुद्रामश्चाय॥ ~८॥ ८३
मुनिक वनिर्ग्रवियय मुद्राङ्गनामराजा मद्वितिक्षयक्रमनागणवज्रगाया चनि की सभमाः
वसिमावल्केन॥ ॥ सुस्थितर्वनिर्गवध्यामु मुद्राङ्कनामराजाध्ववादिषिकयवामलः

मुद्रानामागावीवसाथाविंथावसायादय्यादि॥ ॥ सर्वावस्थानाम स्वयमुक्तमवस्को वक्तवि
कर्यां हुंकि याधनामुध्यानि कद्भिगुणाम॥ ॥ वज्जनमसवर्धवयुवमवयुद्धविषी
मिवमुखनक्लडायवध्वं मुद्धितिंकुवनधार्वकास्यं यायावी॥ ॥ वज्रवज्राक्रय
स्थानं सर्वश्रेयां हृदमामाश्वा यथावा श्रीमानायवं॥ ॥ थथ्यज्ञावाक्यावन्सबवंध
साधनजवयाहृदसास्वंडयायथायाय मुद्राबाहुनयवर्दं सुवमाश्चाय॥ ॥ वज्राधी सरयमाः

*का

हा॥ वज्रसत्वं कंपयामि॥ ॥ बुद्धं त्रिलोकावभासनं [illegible] नाथं वन्दे॥ ॥ का:
[illegible] विश्वावभासनं॥ ॥ [illegible] वन्दे॥ ॥
द्वि [illegible] विमुक्त्या [illegible]॥ ॥ द्वि [illegible] विमुक्ति [illegible]॥ ॥ [illegible]: ८४
[illegible]॥ ॥ [illegible]
[illegible]॥ ॥ [illegible] विधा॥ ॥ [illegible]:

[illegible] नं वन्दे॥ ॥ [illegible]
[illegible]॥ ॥ [illegible] वन्दे [illegible]
॥ ॥ [illegible]
[illegible]॥ ॥ [illegible]:
[illegible] वन्दे॥ ॥ [illegible]

॥ ॥ तत्र सूर्यगतानां मण्डलवर्त्तनं विगाह्यतं खड्गस्थानं धातव्रजमासव्यायाथसं ॥ ॥
क्षितिगर्भतलवासव्यथानि ॥ ॥ हिमवत्स्थानतं धरं ॥ ॥ तस्मिन्काले गन्धवाहविजयवत्
आवीतगन्धनाम ॥ तत्रवीतयुवनामिमहानागवत्तुंगावतानाम राजपुत्रशताधिपति ८७
स्थितः ॥ ॥ यस्मिंस्तं कालसमवर्तुं भिमावीवसन्तानामराजाधर्मराजास्तंवीवपुत्रनाम
महानागवत्स पुण्डवतानाम राजपुत्रत्वं राजाधिपतं ॥ ॥ तस्य महाबल स्म पुत्रशास्त्र

नगरं ग्रामणि विशोधयावनतां वावस्थवतीनाम वनिर्धूतीमववतावयामास ॥ ॥ अथ पुः
ष्पवत राजाज्ञा महाबलवत्कृ धर्मवत नगरग्राम स्थानं नारदस्य धूर्याः सुधावतनाव श्रवतिनाम
वनिसाक्षवयतां ॥ ॥ तत्र स्थत्कृष्णाङ्गवासनबाह्यलिकमाखि स्कन्धायाञ्चकन्धविधिक्षिव
वान् ॥ ॥ अथ राजपुत्रस्तंपुत्रकथाश्चदावक्ष्वसूत्रविद्यादावबामनयीतवचयविश्रुदृति
न तवत नवक्षुव ॥ ॥ तस्यापितावश्यवति रूद्रवताञ्च मद्दक्षाल्याव भवयतावसुदेवी:

श्रीवत्वद्ध दयावद्दवविक्लोंसवनु॥ ॥थ्वयावथ्यवकिराजयवक्याराजयानक्र्यउतीनदोनः
व बर्द्धघनवामवाघ्नन थ्योगुलयावह्न दयमवथ्वथ्वयाडोव राज्यपुयाववन नवन॥ ॥
वदुर्क्क॥ नस्थनामथियथ्वगिछ्नु थियावायिनथियका॥ गावस्र ध्यामिवावथ्यथ्व राथ्ययक्तिनवां: ८३
नवां॥ ॥यामाथ्यंथ्वसा मिसायामययानानंमद्व ययांमद्व गथ्वथ्वस्सासानवनाह्न व
स घावद्धाव हूंनबद्धायाथ्वं॥ ॥अ्थदुतीववनंग्ल्ह वावथ्यवस्तुवार॥ अर्हयाद्विवगा

॥ ॥थ्वनाति क्राहुतीयावनदंदावनाद्वथ्यवनिनथ्वनझ यनित्रवाथ्वनां॥ ॥:
यमथ्वासासाथ्वयायापुह्न दक्कासासाथ्वयायपुजाव्वकि॥ सासाथ्वाथ्वायकियांगासासाथ्वायायः
कियवाथ्वे॥ ॥थ्वक्षीन पुद्वस प्राउथ्वनिदोनयावथ्वक्षीथ्वय थ्वक्षींग पुवजा
ययययवावथ्वक्षींथ्वयथ्वक्षींग पुसामवसंमझयावथ्वक्षीथ्वय थ्वक्षीयमित्रवाः
ज्ञव थ्वक्ष्मीथ्वय॥ ॥नमासाथ्वकिविकिदथ्वं ययांकलीमनथ्वकि॥ अग्निसाक्षिवः

मध्याह्नकालो दिग्भवनीक्रियस्थ॥ ॥अमृतायस्थता विगतमित्रत्रायस्थतायस्थमिवाविरं
वामि॥ ॥वज्रधृकं॥ज्ञानीनस्थारं॥ ॥तथागतानां॥ ॥अमृतस्थानयस्थाधर्मं॥ ८१
॥तथागतं॥सत्यवचनानां॥ ॥वाचस्पतिनयस्थसत्यधर्मं॥ ॥तद्भूत्याम्बरा
तुंगनैवेद्याविधि॥ ॥ज्ञानीनवज्रयुक्तनवदावश्वकान्तनवानां॥ ॥
शुम्भनवृतनं॥यथासमानीयसना॥ पूर्वमग्निविधनवनां॥ ॥शुम्भनलस्थाधावथ्वः

वयुसमिनव्रह्माय नयवाववियनवावाश्वधनं॥ ॥तथागतं॥डयायनादिच्छः
स्थं नवगङ्गंयवाज्रैवाथायुवान्तनदवादस्नियङ्गुनायवलना॥ ॥वगथ्वावाडः
यायनज्ञिबनवनथेवनन्तमजिवज्रैधूकनडायायनमन्नयन्कसणाक्वं किसिभावव्वादव
स्वा॥ ॥वाज्रयुक्तावनति॥ वाथमवनू॥ ॥वाज्रयुक्तनधावञानाय्वनाथ्वधनं॥
॥क्कुनीनीनावथयथि॥ ॥ज्ञानीनस्थाव॥ ॥अग्निज्वलावथयायभूवानां

महस्थि॥ ॥स्वस्तिसंस्थायसावल्मावस्थवल्सावयुवजिसवनामहस्थिवसयसंधांस्य॥
॥वमानाक्ष्मसवंह्रूगनासाश्चिस्कयस्थि॥ ॥श्वकिसियस्थवसायस्कङ्गंसूवानवि
स्कवयव॥ ॥यदयंवनाक्ष्मूयायनग्रियव॥ ॥थ्यकिसिस्थूडयायनस्वायस्थवां॥ ८८
॥वदस्वावसवद्धनमासवद्धूसवस्वस्मावजनंसवसि॥ ॥स्वयाथ्यथिंमूनवी
यनश्चियावमाजवस्कह्रंस्थूसावजनमावस्थवं॥ ॥वनक्रजवायद्धसूगनानयश्चिजिह्लावं॥

॥थश्वङ्गंस्थवयनिस्थंक्षयावयाथ्यकंबूवस्थमस्थनयश्चिजिह्लायावं॥ ॥मयावृद्धि
यजावायस्थमवस्रंसाधिजयं॥ ॥ङ्गवृद्धियायक्वावनश्चविसिमावक्वमायसयस्थवं॥
॥स्थनक्ष्वंसवस्कक्ष्वा४वायूवजिसवास्वासमिसयंमवासाख्यंङ्गनंयुगथ्यावाय॥ ॥
थ्यनलिश्चवंक्षवाउबङ्गंसूकवायूवजिलवाकिसिथ्यासमिबंयवंदावश्रूसाङ्गयुसमनग्रवा
स्थिश्चिववाय॥ ॥रद्धवस्थियसादंक्वूय॥ ॥शावाजासवासयंस्वयायाक्रनयवं॥

॥ दशिकुप्त॥ वाश्वं॥ ॥ विमितलब्धा व स्तु सघवं॥ ॥ सर्व कजं स्तु वा दं॥ ॥

शुं यालब्धया व कजं स्तु वा घवं॥ ॥ सर्व वलयवे ठ यक्षु रिठ मिलिक्वा यस्था विक्ता इदं॥

॥ समसक वलव व यक्षु भलवयं ज स्तु सं दवघवं॥ ॥ यथिमा वासाव स्यु लं नाया ८९

वि॥ लक्षा टविवा जा कि विकं जवा नस्ना मितु लाया स्वा ला नि युयि व ठ॥ ॥ वाजा मव

यवं ब्रायमजिवघवं थवना क वम वाजा कि यवविय स्तु वया वसा स्ना मितु नक्ष घवं:

निवुयया इं जिस्तु सं दवघवं॥ ॥ यवस्था यक्षु व कितु लावावे वकि तु ठ स्तु याय:

वा यु॥ स्यम्भि वाली विक्रुगलवस्था मीयु स्ना व तु वि॥ ॥ गथं धावसास कलवक तु:

श वक्ष व कि स्तु ठ यवायि स्यम्भि वलीकि मवक्रव थक्ष स्वा मिया यक्षा जवयघवं॥ ॥

स्य व कक्ष॥ वाजनं यस्व में श्चि कना वा थ्यो लक्षा घवं॥ वाजा स्यम विला वा स्मि क्रमा वा थ्या विवक्षा

स्वनं॥ ॥ ह्रया वाजा निवुयया यथवनी स्त्री थवनवयव वाजा क्रम स्वा क्रुसं क्षा थस्मिङ्ग:

वढव यानस्त्रि यानधतस्थं नवा॥ ॥ग्रुस्वा॥ यथैम्नः ञुं वरुवानां माश्चवसुथिवी यविठ॥
विवम्ना यढिस्यौ श्चक्षी यवानरुवनो॥ ॥विं रुा॥ नियकविययम्बक्ले यायमारुु
यायजा॥ जगविययवव क्षस्मि नून्न वक्ष्मायु निर्दिवठ॥ स्तगमायि विवनाबा याविवं याधनवा: ९०
यविमयि जननावी रुद्रुनी याम्नयिमि॥ ॥वस्थम्व॥ नगवबानविवनमि नश्वस्तलाम
ब्रवमनाग्र वानिस्वु ब्राायवनिवठ॥ ॥थ्वनविदनग्नवला मच्चावल मथ्वनवियाः

ञ्चथ्वधवंश्च यावजंभूक वनं॥ ॥नवामो बाञ्चवा वारुा मूठवायु ववि नवठ श्रूञवववलना
मद्धायंवनिवमूठ॥ ॥मच्च श्रूमावविमधनाविश्चयं यञ्च यविवाद्वं॥ ॥थ्वथ्व
जंभूवनथ्वायाद्धाव बाघयानारु याञ्चन वायूवविनवा दमिजं वूवबावायायमश्चवरः श्री
यंवद्धाव मनायंञ्च मवाम॥ थथ्व मम्नयञ्च मनादाव क्षिमिनश्चाव माभिवजंभूवञ्च मथंमयं:
कमारु भाम्नुडयायवाययवं॥ ॥श्रूञ्चवनविढ्याविद्धिवांव ॥दवमम्नवूयु

९२

यथमि॥ ॥थ्व बाज्रयुक्त उअव ताय्यं थ्व कृ स्त्रीस्त्री थिं मथिस्यं वस्त्रा नां का नविया व युक्ता

याढाव क्रान माक्रन मवन मवनवं थ्वकुस्तु वं॥ ॥अु थ्व वनिस्यू याह स्त्री यज्ञा नविष्या:

मा ला ना ल्युं स्ते व नाठ स्व ना थ्यो मानिय ममयिं मवानु॥ ॥थ्व युवानम यूनां मयास्यं:

वस्त्र मिमल्हि व वियाव य्युव स्वदाव वानिस्यू कद क्लिमा मख वना वयं मा कयाव न थ्वयस्वीयाद:

कयाव विनथ्वयं॥ ॥मव बाज्रयुक्त स्वांहव यथ्यांया बाव थ्व वनि यनिहा याल्युय निवं ९३

य मा नि ग्रुझान स्त नि मि वल्ला वन ठ य थ्यांक नि सगाद॥ ॥थ्व बाज्रयुक्त स्यं थ्व वव

स्वह्रव यमायिय अ बाक्श्युं वनि श्याव व यहव व क्वा व वं ग्रम याढाव ज्ञान स्वन मिस्रा मि

ज्ञनं नि स्रं ७ व मदन॥ ॥ना मा वा स्त्र व मि स्यूव श्विव लि स्विन ॐ व नि व ल थ्व नाम ठ ४:

यवं विवाद मयाग व॥ ॥थ्व हलां स्व याव व नियुक्त थ्व बाज्रयुक्त याक्त थ्विंयु स्वमन

स्कुयाय थ्व थ्वायन थ्व अल्हान का वयं यव मावियाद याढाव व न थ्ववं॥ ॥मथ्व ल्व यावि

स्वितामिति॥ ॥ह्निरग्नवानरव्युयवानवद्दानस्थुं थथ्यायासंक्रायद्वयुस्वनथकं॥

॥नह्निरवनवनमधियेग्यमदनारव्यनसस्व ङ्कुंवसमन्द्वर स्त्रंजानाशियमल्लक्रायवनि

नक्षा॥नयिह्निरग्नवारद्वमनयद्यूंवि॥ ॥नमक्षवमायिग्राह्वेनवाननयद्येनवाव: ९४

च्छ्रंयाख्क्ष॥ ॥थ्वयवानमल्याबावमन्द्वनजलाशयमारवंजालमाह्निवंसवन

वनाक्वसअमन्द्वरयानथकं॥ ॥यायवंगृह्निताडल्यथ्यधनुयिवध्वागास्थल्कु

स्योकुलायुक्तहिमुस्वंयस्यानक्ष॥ ॥मन्द्वनसाडावकायावविधासयायवनाक्वसत्र:

मवयंकहृनंथ्ववयुह्ववनयाडं लंनवल॥ ॥अथनमूयावायमामूयवाक्षयविधियाव:

मूयवया॥ ॥ध्वनलिख्वमन्द्वल्नसाडंयडावववानाख्वमूथ्वसामाखुविधियादिक्व॥

॥नमनयच्छुयूह्निरग्नक्षाविलयनि॥ ॥थ्वमनूथ्वनमन्द्वनसाडावडाडाबह्नि:

ग्राह्वनविवायथाव॥ ॥अकाल्यनुस्स्थ्वनयावद्वक्कमध्यमध्यदंयालमिवाग्नीक्रया।नावङ्ग

हिकीयं समूयस्यीवंम स्थितु स्वनश्चैवद्धा नीलवन्ति॥ ॥ स्वनावस्तुयलिमिवं नागवव निर्दि
स्वव॥ वदकाीलिमवोद्धा द्दिमायस्मियिनमूक्वलि॥ ॥ नमावविनावावमू नवानस्थिनवाः
ल्मनि विसवामस्वाद्दस्व८ यूंमायाद्दमिवस्थ नावडा॥ ॥ मूद्धावीविस्म स्मानमद्दद्दवं॥ ॥ ९७
दिवथ्यकल्वयिमस्वकवायाव विस्कवयावथ्याव॥ मथिंमुज्ञ दूद्दवथवं॥ ॥ स्वकमिमस्का
नाविवथ्मिवानिवावाक्ववावलिथु वगुवानि॥ ॐ देवद्दस्मुानिमयववानिज माक्ववानिवंदः

गाक्कवाणि॥ ॥ मस्वस्ववा॥ ॐ हूं मश्वे वक्षु॥ वायसन्निदिवायायथ्यमस्वदं८ यवमायवांम
मागमा८॥ मायवद्र माथ्यस्वमूयादिगु वंगुवुं॥ यूनविमुस्वज्ञहिद॥ ॥ स्यावावात्रिः
कयवानं यिमिविस्कस्कवांजनं॥ वानवलमिदंवय्यं मित्रमिथाक्ववस्वयं॥ ॥ विंका॥
मिवंथीमिवमायनं नयनयावानस्थनंवकस८यावंयम्लस्वद्दू८ स्वयाभ्मद्दव ववमिवथमद्दन्न
कंं॥ यवायमहद८ समृद्धिसमयस्वयाजिलायाज्ञला स्वसवेवमिलाङ्किवल्वानिवास्वयाद्दन्दः

[illegible]
[illegible]
[illegible] ९६
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

धर्म॥ ॥गमाहं मद्भ स्वयव थनंड्ढमासि॥ ॥थ्वनज्ञन मन्ह्व थ्वा द्विया धवाय

धर्म॥ ॥चिताङ्ग लघूयगन वाखां मन्व थंगल्वाकथ्व मूकिस्थि भसाति॥ ॥थथ्व

द्विव थ्ववानहादाव विताङ्ग लघूयगनवाव मथ्वनवहाव थ्ययवावनथ्वा नधर्म॥ ॥ ९१

मथ्वाधम्थान्ह यानिथं चीका गवाव थ्वकाद्रयविष्ठ॥ ॥थ्वमव थ्वया मायाव लंथ्वा:

ञावसिमाक्व मवानवन धर्म॥ ॥गथ्वविधं मृगमयथ्वव॥ ॥थ्वयवावक्ष सिद

थाद मृवा मव थंथ्वल॥ ॥वगवाकिवा मादाय यद्ध थ्वमना मृथ्वाक्ति कंवलिमं॥ ॥

थ थ्व मृवासि दथाद थ्वथ्वंसाव वमवा याव थ्वा यिवा यावमृ गथ्वा सामिथ्व सावन धर्म॥ ॥

मृत्रान्व द्विव थ्ववानाया थ्वद्वि नाव थ्वथ्व मत्ना थ्वगोयंजरा ग्रयं त्रवग॥ ॥थथ्व मयव

ग मन्ह्व वा वमं ताथा ववस द्विव थ्वकवदाव लियाम वथ्यंक यायुवि थ्वहाव मंन्हव ज्ञल:

समथ्वनन द्रंहावं॥ ॥मृयाथ्वा मनकं थ्याधमवला थ्वकडह्वयय लायित॥ ॥

[illegible]
[illegible]
[illegible] २८
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

सम्यग्दिनं ॥ ॥ थ्वनं [illegible] नं नो [illegible] या व

विष्णु [illegible] यिना याथ्वनं ॥ [illegible]

[illegible] ॥ ॥ विष्णु सम्भो [illegible] ॥ ॥ विष्णु समो: ९९

[illegible] ॥ ॥ [illegible] ॥ ॥ थ्व

[illegible] थ्वे:

[illegible] ॥ ॥ [illegible] ॥ ॥ [illegible]

[illegible] ॥ ॥ [illegible] मानः

[illegible] ॥

॥ ॥ ॥ इति द्वितीय [illegible] मित्र [illegible] नाम [illegible]

[illegible] ॥ ॥ ॥ श्रीरस्तु ॥ सम्वत् ८०९ [illegible] मास [illegible]

यक्क यकास्यां वृद्धस्याकि दिग्रसंयू॥ मिमि॥ व्यानयाकि वगुयस्यन कर्छं ह
का खाव स्थायाय का गृह्ना वस्थि न ध्यम्योल्मा श्राभयाव ह्मानवाज याया इन्का यं थ्व हिमानावीरु
वन यथ्यांन्हि ह्मायानाम मन्हायूथ्यक्वन श्रीश्रीश्रीजितमल्ल मोव्लि वंडासानस्त्र पथ्यननालवस्तु १००
कस्यायास्यं वादानवस्य थवन्हु उद्यदग मन्छ्वस्वन ध्वमयथनगाधनसावन्वाज्ञ या॥ ॥
अनुगमनतंन वकुश्रवंदा॥ ❀ ॥ १॥



